CHUNILAL GANDHI VIDYABHAVAN
SURAT.

Manuscripts Library
S.D.P.13

Coll. No. 160

Title Laghuśabdaratna

CHUNILAL GANDHI VIDYABHAVAN, SURAT

Shastri Dinmanishankar Pustak-Bhandara

No.: 160 Subject: Grammar.

Title: Laghu Śabda ratna

Author: — Scribe: —

Date of the work: — Date of the Ms.: —

Place of the work: — Place of the Ms.: —

Size: 9-5 x 4'4. Extent: 44 Foll. missing. No 29 & 43

No 31, 33 & 34 are numbered twice.

Language: Sanskrit. Script: Devanagari.

Remarks: Incomplete. No 29 & 34 missing. No 31, 33 & 34 are numbered for double foliation.

श्रीमहागणपतये नमः नित्याधिकार इति उपपदमतिङ् इत्येतत्सूत्रस्थार्थः निपात इति अप्रति बहुप्रसरं नित्यस्य र्थः एवंचाधि
ते काराप्राप्तमपि नित्यपदं तद्देशेन संबध्यत इति भावः योगविभाग इति तस्य चैकेकस्मिन्नविवक्षते एकपदीति छेदस्येवेत्यर्थ इत्य
र्थः एतद्धु ताच्छ इस्येवेति प्रतीकप्रा योगसकप्रमाहात एतन्वेति उक्तं छायादसत्वनित्यर्थः निपादइति अपितव्य नित्यार्थे कोपा
व वाचकस्यापि नपुंसकत्वं दस्यापि प्राप्तेः पदिकल्पेन त्वेन लुका तदम्भवराहित्यर्थः अमरथ इति सुवंत मित्यन्ने नान्यतरस्येव ग्रहणा
विनियमकाभावादिति भावः यर्थ शाइस्येवेति तस्य कालवाचकत्वेन क्रियायां विशेषणत्वादिति भावः कविकल्पएवेति काशानि
त्के इस्येवबोध्या योगविभागसिद्धत्वात्तदस्नु वादेन विभक्तिलोपस्ये वानेन विधानमिति भावः व्यत्ययोगादिति समासे हीव
ॐ म्यापरनिमित्तः स्यादिति भावः अन्तोपदेश प्रत्याहारस्य समासावयवविभक्तेरेव तेन समासोद्भुतस्य स्यापादिति तेन भवत्ये
व मन्तुगापवादर्थस्येवचिन्त्यो गतिसमतुरोयोर्थस्य विकल्पेन भिन्नो तासु परस्मान्यपदार्थोपसर्जनत्वमेवेत्स हचेत ह गोरीपतिरिति ग
त्य जेकुमारी पुत्रेस्याप्रयोगास्तस्यमादिकत्वलाभापत्तमस्त्यपदपूर्वपदत्वकरणा उत्तरपदस्य तदोरिति समासकथनं उत्तरपदस्ये
वृत्यालस्य सम्भवात्तर इति पत्र इच स्वतस्तदेवरूपमित्यस्वपः तन्निपातनादिति उपस्थितत्वादित्यर्थः परिशिष्टेति
ति ब्राह्मणादिः स्याद्देवदत्तसमभिव्याहारेण ह्यम्भनियम्य वाचकत्वेपि संनिधानसागेनमानमिति विग्रहपा
१

निषेधोपीति। अत्र पंनाशाबार्थकनञः क्रियान्वयित्वमुक्तमित्र इति भावः। नवा युक्तीति उक्तव्युत्पत्ति विरोधादिति भावः ६

ग्राहृत्वेन: गादिति एवं चविग्रहे इतिनञ्युक्तिरसंगतेतिभावः नवेति सेवेति एवं ता हृशविग्रहस्य व्यूह कल्पनमसंगतमिति भावः अत्रसम
र्थादिति एवं च तत्राधिकयत्नत्वेनैवाभावेन तन्मात्रत्वेन नियरसंगतेतिभावः तुल्यभत्वापत्तेरिति तुल्यत्वेन कृतेकोदृशोकास्य
वल्लुकापहारेणोतिभावः येकल्पिके डादिविषयेस्वेहत्याहावल्लोकिकत्वस्यापाप निर्मिति अथैति अनभिहितमत्वेभाव्ये प
रिणामानफलस्य भीष्म कथमिसस्यान्यथा सिद्धित्वेत्राना रक्षितं भयेइति अत्राह विवीजेनतुम ध्यार्थकस्मपयोगोहित्नी
याविधानस्यद्वारार्थकारणक्षुपयोगेपंचमीविधानस्य चारितार्थ्यमिति भागुतेरित्या अथविहाय तेनोक्तया अधिकारेण
नीति कालवाचकत्वादित्यपि बोध्यं क्रियापरेनैवेति कर्तृकर्मकहा इति भावः ततोमतत्वाधारकघटाभावमत्नीति
स्वाप्यतिबोध्यं भाष्यकारेति संज्ञानुपपत्तिस्थानमित्याहेषत्वाभावांर्थेति तहेशयः अत्र अर्थंत्रार्थमतीति वाक्यम
तिशाब्दस्य सादिमन्तनु रक्षितानुसारीतिबोध्यं माषकल्पइति पर्वाहस्य परित्यज्येप्सयैरतिभावः अत्रोत्तरिकल्पइति
उक्तवेगामित्यादेय्याभिचारादिति भावः ननुनित्यंत्याहेग्रहणपेनमत्तीत्यत आह इत्यादीमिति तदर्थं तस्मातिपारके
अतत्वविवक्षायां तस्यापि विवक्षाया भिस र्थः यथापंचेतमिति तद्वत्तमित्यर्थः अतत्वसमस्तुतममिति माध्यान्येनेत्यर्थः १५०
तेनेति अत्र तत्वस्येत्यर्थः तनुसहाहृसांतत्वाचक्रसाम्यावेतेननसमासोनस्यात् अग्नि मपपयंतमिति विग्रहप्रदर्शनेन नमवत्ता

दि३

पितस्पतीकाराग अग्निरंनोमसेपतस्य त्वदुक्तविग्रहसमा [illegible] ना [illegible] र्थेतदित्यत आह सहसुपेति एवं च प्रथमंगतेन समासर
त्वसंगतं। अंतंसाहित्यं च सहस्थाद्यर्थः तच्च च सत्वे विविलामनाविरहात्स्वत्र्याके सहस्रष्ट स्यग्रहणमिति भावः हाकल्पस्येवेति थं२
दो३ पक्षणामिमपैतस्य कथमन्यस्य सरित्यजैतिपतीतेरिति भावः एवं च पत्रेनतत्वेन रूणामश्रेणो नास्य पभितिग्रंथस्यवितसाहित
यंना मतत्तोनतात्संगेत्यपिचेत्तनीर्थातहिंयचांतेरपिमोसतेतपक्षकथनस्त्तीये तितात्पर्य साहित्यघोत्यतिनियमात पेत्यर्थः मपूर
स्यस्कादित्वात्समसः पंचोछतेतुपत्रहयस्य सहासे पूर्वे पिसाहित्यप्रतीतिर्नैव तेन तप्रतीतिरिति तस्य तघोत्पत्तोकिर
संगतेत्वसाहितिदिक् समाससंज्ञायामन्वयोति एकार्थीभावविषयेसंज्ञोभावेऽस्पसर्वदानिष्टत्वेन संज्ञायैवेनतद्विषयेको
यमितिवाचितिबोध्यं न्यायसिद्धत्वमत्राह वचनं विनेति विकल्पसोधकशब्दं विनेत्यर्थः नित्यत्वात्वइति वाक्येनसंज्ञानव
गमान्नित्यसमाससहरात्वेननित्यत्वादित्यर्थः पुनर्विधानमिति समाससंज्ञापाइति भावः अन्यथा तद्धिहि तसमासा
नुरोधेनाव्ययीभावादैसंज्ञामेवविदध्यात् अत्रेचक्षुस्यानमेवशरणंहृष्टानां नचैतत्संज्ञाविधानमव्ययादीनां समासे त
शास्त्रे प्रथमानिर्दिष्टत्वं समपारस्नेनोपसर्जनसंज्ञार्थं चरितार्थ्यमितिकथमितिवाच्यं तत्समासे तेत्र्यस्यसमाससंज्ञाव्या
प्यसंज्ञाविधौ प्रथमानिर्दिष्टमित्यर्थं बाधकामावादितिदिक् इत्येव समासस्य [illegible] का [illegible] चिके त्वेह तमाह जीमतस्येवेति

२

लघुशब्देन्दु अनवच्छिन्नकारिति वहियोगे पंचम्याः समासविधानात्त्वाय कारित्यर्थः अनुसरणात्संबन्धानुमन्निमित्तेन नुतेन संबंधेनान्वयस्तदाह
अव्ययमिति अनोः समीपार्थत्वादिति भावः वनस्पतिमिति कर्मप्रवचनीयसंज्ञानुनात्रभेदेन लक्षणाद्वेनेतरत्वान्वयो
वानदनेऽत्रालंबवत्स्य स्वनिमित्तं एवं चात्रापि तेन संबंधेनान्वयोऽन्वयो वान्न कर्मप्रवचनीयत्वप्रयुक्ता द्वितीया सहैष्या
घं नमेद्वा दृढे कार्य्याभावत्वात उपलक्षितेनास्य विशिष्टस्यार्थः गंगादिद्युम्नदृशोत्तरे द्विगुत्वेत्यर्थं निपातनमन्तमात तद्गुणत्वाप
कत्वबोधात्मप्यानुयोगत्तोऽत्राप्रयोगोऽस्य तत्त्वतिक्रियाघ्याहारकत्वयोः शब्दस्यारम्भद्योतकत्वेनानुतज्जन्यबोधकत्वकेव
लवत्तिपदार्थघ्रितमिति भावः समासस्येति इहं च समासोऽयं तत्त्वादिसंबन्धेषु भावास्वेष्ट समासार्थोत्तरपदस्यैवेति अपं
प्रयोगो द्विगुरितिसंबंधे केपंटे स्पष्टः परत्वविंसः समासेपदस्य तदर्थो नरप्रवृत्तत्वप्रयोगाणामाभावात् तदर्थबाध्यस्योवा
दीनां समासपदे नवहणा नित्यसंस्येवगो द्विगोरिति भाष्येतु भ्रंबाद्य अनरहति सत्त्वस्योत्तरपदत्वकल्पसूत्रविरोधाद्व तेषू
नपत्ताघपद्ये स्वफलेऽद्यसमासेतेति अर्थतावपूर्वीभावत्वप्रयुक्तोऽत्र द्वितीयत्वमपयुक्तो द्विप्रेषु सुः जनोऽविधुरीस्या
दाचकारश्चोत्तरपरत्वाभावोतस्त्वात्कथं स्यादिति वाच्यं लिंगानुशासनेऽस्य त्राणालोकसिद्धलिंगानुवादकत्वेनाविधायक
त्वेनवान्येत्र द्विगोस्वीत्वाभावनिर्णयत्वाभावात्तदुक्तेऽनिपातकत्वाभावात्तदुक्ते लिंगमशिष्यंलोकाश्रयत्वा लिंगस्येतिस राम

३

लघुशब्द पे समासपत्यपेतिनिषेधरीतितात्पर्यं सदुत्वनोरिति द्वीपमन्वयेत्वास्त्रिन्तेरिरपिपयोग्धं नवियोदिति श्रितशब्देनसमासेतत्रापि
समुदायसापेक्षत्वेन कोऽदोषः नवमापेक्षत्वेन काऽपि शब्देनेकार्थीभावापन्नत्वेऽगमोपत्यनिश्चत्सामर्थ्यत्वेनकार्थीभावा
दुरुपपादतेति असामर्थ्यमिति तत्र पर्यन्तेत्तरावयवस्य गौरवेऽन्यापत्तमित्यर्थः परमगाउपयोगाऽतिप्रसंगस्यापेन विधिरिति भाष्य
समतत्वेन तत्रानुपपत्तौ निषेध्यकार्याभावाभावविपिपदार्थकर्थविदेकार्थीभावमाहापेक्षतेभावसंगतत्वादिति येन समुदाय
दृश्यपितदादिनियमोभावेनकेवलाद्रापत्तदुवांतस्वमिति देव सन्निनमेऽपत्तेश्चागोत् विविधि द्विगार्थेस्तुउपपदसमासादि ति
सत्त्वस्य नषेधे समासातुपपदे समासांतरागवादिस्तुतराणापथवाविपाद्वीसमासापेक्षानसेतदेपपदसमासोऽविषयीतीनिभा
ष्याप्रयुक्ते च चिन्त्यास्वकोपादानेपित्तसारिभाव्यामप्रतिः अर्थे समासेऽपि सत्वनुपपत्तेः पूर्वमेवगतिकारकेतिसरस्वेषष्ठीसमासे
पोत्वभयोः समत्वेनान्तरंगत्वाभावेपित्तस्तिः ककर्तृपोरेवाभाभ्यामेविप्रतत्पाविरोधाभावेनषुगपूरुवोभाभ्यांसत्ताद्येनाते
पत्तालुषसीसमासेनानेतत्केकार्यीभावात्तदेपपदसमासेतत्केतेकार्थीबोधविप्यतिस्पास्यानीतस्यर्थकेनपघपिपपाणानि
त्कादिकापदानेपितत्सजिन्निरितिनन्पत्तलयापित्तदेदुत्के प्रयोजनाभिद्विरिवाक्रदूषणामिति एवंचेदृशेषुसपेक्षासामर्थेपिनस्य
तिनफलमिति तनत्कुखोगत्पर्थत्वाभावात्केतरित्कः कथंपाकमी द्विनीपेत्यपात्ते पदेति अत्रापिपरत्वेफमानुकेऽव्यापा राम

३

मासांतात्स्यादित्ययेषुमाष्ये नवोत्तरपदग्रहणवत्वे पिञ्जवपत्वायत्वस्यसमुदायस्याप्यत्वेनोक्तप्रयोगापोः सिद्धिरितिवाच्यमंत्रतरति
सन्नेसमासांतोग्रहणत्वमुत्तरपदस्यैवेति विकल्पेश्राधिरुद्रंप्रथमकारस्योदोकोपोनेहमत्वायमिमुक्ता सुनहोत्तरपदस्येत्युक्तान
सक्षिप्तत्वेदत्वनांजेगहानखाक्षिद्धि रिसर्थप्रसमासाविरोधेनतत्स्वंस्मांगांकृत्तुमर्त्वकृत्वा सिद्धांते उदप मात्रपदइति वाक्येद्वियस्य
द्व र्थः सर्वमहेद्विपाविषयेएवपूर्वे तत्स्यवहारारि तिभावः नर्दभिमिच्छ्रत्यनेकेपदप्येषे परंतुपाणविभक्तासिद्ध स्यसमासनेत्वेन
विशेषणानदीपोराभासीत्येनेनबाधः कार्येनैत्यत्वेदृष्ठमानेफलत्वेनचिंत्य तदेतन्नद्युकोमित्युनेनळ्वनित॥ इत्यपिमाष्टन॥
इतिपदमेतिवित्ति अत्रतुनासुचितमहतिवीजमुक्तो यद्यपिसंभावनेत्यरति एवंचततत्रेतेनसमासः स्यादितिशंका नतत्र
रितिति तत्प्रकतित्वेनेत्यर्थः गार्गिरित्यादिति नदिनविधेतत्पदइतिनाधिकारः तत्वंव्याप्यसमित्यर्थेगार्गीरित्यः प्रत्यपर
स्यर्थेतरथेवाचस्यिलकुलमितिविना समम्हास्सिरिपतोपूर्वान्तरेणान्वेतो तिकुस्मितइतिमत्वेन समाप्याद्वित्वलुप्यनेनतरंसाम
३ म प्यमित्यशृहितापत्यपात्रतिरिति किमर्थंतत्रस्त्रणवृत्तान्तस्यात्तापकत्वायितिविं लं तेनैकपदेति समासमत्यपवि
चोपितिषधइतिवातिकव्याखावसरेश्रितानंतस्यैवस्वेतत्वाभावमास्यकर्मसंयुक्तासंभवतसकं प्रहारइति कंठश्रितःकात्त्रि
तः श्तेत्रेयथास्यात् कृष्णपसंश्रितस्यभवमाभ्युदितिभाष्यविरोधादितिभावः समर्थनेत्युस्यविशेष्यत्वमासाय प्राप्तस्यसत्त्वात वि

३

रोधात्वर्थस्यावशपक्षेवश्यतामांतगतित्वाद्धिनोमेत तदर्थमावश्यकमिदं द्वितीयाग्रहणस्येति चतुर्थीचेत्येवसिद्धेतत्सामर्थ्या
तत्पश्चाद्वाधकत्वमितिसोध्य असमाप्येपरित संदर्शनाद्विपरत्वेधात्वर्थस्यकर्मणापमितिप्रतीतिसंप्रहानत्वेवक्तव्यं तत्परत्वेक
मणिद्वितीयाप्राप्त्विसिद्धमा श्रित्यतत्वेप्रास्याप्तमाको निवेतोति समासहमानार्थकवाकाभावेनतत्वाभिमानः सर्पोद्रारकमिति
गुणेकृवनस्यशच्छ्लादितिभावः कारोतत्तीयेति ननेवंतर्कवाणाइत्येवसिद्धमेतन्वाह सूत्वेवितित्ति वनरूद्धत्वेवित्यर्थः अयुगेवभवा
त्रपोसिरः एतदभिप्रायेणोपाथ्यहणमितितात्पर्यं अस्मानिपुणायोगोहेत्तुलेमभवेपिसर्वत्रहेतुग्रोपयोदनासंभवरूपफलेरा
ह वचेताहूति व्यर्थमिति महोपादपोगत्रेतियोकृततयान्व्यार्थीरितित्तीयानेनैवसमासोनतुभोजनेनहेतुत्वोपयादस्याइ
सादेः एतेनतत्त्वेपष्ठीसमासेनाद्विः हेतोःपञ्चम्यर्थत्वाभावाद्धितिपरास्तं कृत्निषेधपरमिति ऊनार्थकलहंततीयाइति
सत्रेष्यास्यानोद्धनोर्थग्रहणांग्रहितिहनो कृकनोर्थान्युस्मपदान्यर्थकान्हैयशेदतीयांतस्यासपतोहानातीतिस्यर्थः तत्रहि
प्रतिपदोक्तेवादस्यवग्रहेणामतोन्नाद्यसनुपाद्यो भिविपपरंभिवान्यः तत्रीयेतिसमभाष्यत्रस्रमेण्यग्रहणांमसमेव्याते अतत्वनम
र्थमत्रभाष्यत्मीयातत्केनेत्युक्तेयाप्रतिपदोक्तेपरिभाषापेक्षप्रवृत्तिरेवचेतोतत्स्यपोधपर्यवाकृलहोदवृत्तिमितिनाशयः
प्रतीपनेकृपएस्पेप्रत्तत्रमपोदरस्यंचेत्रअधेचितं पूर्वतस्यावेति उभयमप्यापितत्रपादर्शनादितिभावः अत्रपवार्तिकस्यस

लघुसर्व

रि स्त्रे ३

मासप्रकरणेऽदर्शनादाह समेवेति स्वच्छद्विजशरेणेति न संबंधी द्विजमत्तदितमनुष्येभ्यः श्रेष्ठ इति बोधकः। द्विजनरसमु

दाययोरवयवावयविभावः संबंधः द्विजेतरमनुष्येभ्य इत्यध्याहारः यतः समुदायादेकदेशस्य पृथक्करणं गुणक्रियाजातिभि थ २

भाद ३ र्णनात्तैर्वर्तते त्रष्ट त्वकरणं च स्वघटितसमुदायघटकेतरस्य इति [redacted] मतेरत्र पदत्याज्यत्वान्नः मेव धोनिर्धा

रणाविभक्तेरर्थः नराणां मिश्रस्य च द्विजेतरमनुष्यपरता न खोरत श्रेष्ठत्वबोधेन तत्र तिरेतर मिन्न ते श्रेष्ठ शब्देन समासः प्राप्ति बोधरहि

र्दृष्ट्या तन्निषेधमाह कथमुपमेयमनस्ति पर्वमतेन पुरुषस्यापत्यं ने नसामर्थ्यं दृष्टमपारं उत्तमत्त निर्धारकगुणात्वात् निधेधु र

ति इदमुक्तं भवति त्वैर्बोधगिरणषष्ठीमपि बोध्य एवं च संबंधसामान्य षष्ठ्याः क्वचेनामसति भावः सामान्य लक्षण षष्ठी

समासनिषेधो यः महत्तिरीति वेत्तडिक मत्तमभ्युपेत्याप्याह पदेति संज्ञायामिति समासरति इत्यर्थः वारितमुद्

वा ५ नात्मकसंज्ञा त्वभंगापत्तेः रूपात्मकः संज्ञा विहितेन तस्य सामर्थ्यं सर्वनामानीत्यत्र नि

स पातना त्वभावश्रस्य पत्रमाशरायत्वापत्ते संज्ञाकरणे हि शास्त्रानुगते वक्तव्यतिप्रायेण चकृतः सतं च तपः कृत

त्वास्प्येवमसंज्ञात्वेनोक्त्वरणे ने तवमेमत्तेनस्थत्वमिति तच्चात्मनुगतत्वाक्स्विनापेयुक्तौ पात हारणस्प

वाचकात्र्यैवनिपातन्यानीत्युक्तं संज्ञायां तु द्विजइत्यादि नेष्य तस्वाभिधानलक्षणः कृत्तद्धितसमासाश्च वर्तिके कारके राम

इत्यत्र माष्योक्ते रिति हि रु पूरणार्थत्वे न स्त्रे त्वकालेकृ विमाहे त्रि मन्यायसमस्त विषयत्वादितिभावः उदाष्वितिति अधिक

नगुलिन ५

णत्तममा पादपूरणामितिनिर्दिशे न परणे न निषेधस्यानित्यत्वं ज्ञापयति न कुंभ पूरणमवरसादिष्वप्येतद्विच सिद्धमित्यन्ये

भाग्यस्त्वेति स्वच्छसरितत्वकृत्ये ने भाष्यविरुद्धमितिभावः उत्कोरगहरणामेति प्रादहरणमस्त्रकृदात्मस्येत्यर्थः गुणान्वितेय

ति महागुणान्वावितये त्यर्थः पर्वत्रयेति पर्वतेतन्त्रसमासप्रतिषेधस्योक्तत्वेन पूर्वमुत्तमः स्वीकारो विरुद्ध इति भावः भावप्रस

पातत्वेति भावप्रत्ययान्तः सन्नेवगुणमेवाह इत्यर्थः तदाह तत्स्यागुणगमनेति घटस्य शुक्लो घटः शुक्लः इत्यभयविषयो

वे गदर्शनादितिभावः गुणमेनेमित्यर्थः ज्ञानाभिति भावप्रत्ययान्तगुणवाचीति द्वितीयेनाऽस्मर्थात्पातदर्थानाभरुक्तैराः पु

मनसीति शुक्लादिरेव समनेनेवाप्रादिभिन्नेनिषेधस्य सर्वलाभेन समस्यादिपुनरजितमस्तेमित्यर्थः निकृष्टगुणामिति गुणपसं

बद्गुणमेवनाहुः किं तद्गुणातीनाति मा हरित्यर्थः तुल्यो रेवेति तेनतत्र निषेधासामीनिषेध्यते चतत्र समासादि संभवादि

तिभावः संयोनेवेति तत्र हि समक्षकादिरेवेत्युक्तं स्वस्यापत्नमिति भावप्रत्ययान्तः सदा गुणवाच्यमपत्रानिषिध्यतइतरशे ति ४

इतिभावः स्वनिष्ठविशेषप्रतावानेकस्वातीयते इत्यर्थः तास्यामिति गुणपदसमानाधिकरणेपदेन गुणवाचकत्वमित्यर्थः स्वर

मनाशिति गंधमालती कुसुममित्यप्रयोगादित्यर्थः तत्स्येति घटः शुक्लस्त्या रोगुणस्यापितेः प्रतिपादनादित्यर्थः श्रोमेर

ति तैः सर्वगुणप समानाधिकरणास्तेन गुणोसमप्रतिपादना दितिभावः समानाधिकरणपमस्त्येवेति भुणिनामनाधिकर

लघुशब्द

णप्रतिपादकशब्दावाच्यगुणवाचकत्वं तस्य त्वं नैवं शोऽक्तमादित्यत्र स्मिन्गुणिमात्रानाधिकरण्येन प्रतिपादकस्याऽ
दिशब्दवाच्यगुणोवानेकत्वादिति दिक् तोऽर्थस्य संबन्धस्येति अत एव गुणेर्थशब्दस्य गुणेऽपि दृष्टमिति विग्रहस्य दर्शनं भाष्ये न
वेपञ्चोहितिति तत्र पञ्चादि निमाव्यपरपर्याये श्रोत्रादि लाख्यमानात्तत्राप्युपपत्तौ नियोगपत्रमीकृतन्नेमानाभावइतिभा
ष्यप्रयोगापीति प्रकृतेत्र नूपस्याभावत्वद्वारकोपीत्यस्याप्युपलक्षणमिदं केपरेति उक्तमात्रारूपविषये तस्येनेति यद्यपि
वोषकृष्णोनत्व समेरस्तथापिकारकस्वस्मास्येवसमासत्तिषेधश्चाविरोधाहुरपोऽपीतिभाव: सतिसमासेइति षष्ठी
समीसेरस्यर्थ: तच्चेति तव्यवस्थाऽऽपूर्वात्तिरस्यर्थ: अप्रधानमुपसर्जनं मिसंन्तर्थतामाश्रित्य षष्ठीसमासेऽपि स्वचाभि
निपातव्यो एषवास्याप्रभावो बाहुल्यकारत्वे कारेपि इतिभाव: तकतेऽर्डस्येति आसौ दिस्यव्याहारात् वातस्य व्यव
मत्तेकारतिनवाच्य: नचेवमर्थान्तरे तत्वापूर्वेऽतरत्वकर्त्तत्वीयाया एवनिर्णयात् सामान्यविषयकत्वस्य चेति वि
षेयत्वसम्बन्धायामनुवाद्यविषयेइति सम्भावनातो आप्यतइत्यर्थ: पौर्वापरे: तक्के कोऽविन्त्यापनवर्तमानेनेन भते कोवा
ख्यातत्त्वितकेमप्याप्यतक्के कोनिषन्यायोऽयमिति सामद्दस्यनेन समानविषय: नामामेदाभिदस्तेति केहाननोरम्प
तेरतितेनयुक्तोऽरधिबाध: प्रकृतेऽतत्व: अप्राप्तायामेवात्स्योपधाहद्दोक्तावामादि इह द्विरभ्यतेतो श्रुतेरस्यारावतो

१४

अन्यथाह आह नर्थकत्वर्थस्येव य इत्यो सिद्धेक त्वरीति यदर्थमिव अन्तरङ्गेति अन्यथानेकर्मधारयान्मत्वर्थीयप्रसङ्गेन ८

नतत्कोऽर्डियस्यापेनतयात्तयोर्वोधइतितत्र हि नेषवाभिति मन्वभाष्योक्ते: अत्रवतेमानकस्यभजतेनामोनेमाहमासवर्त
मानस्यभवपायुगपद्विवक्षायाम्ब्रसंभवात् पूर्वं द्वेतस्माद्धर्तमानेनेत्यादि तितस्यवायमर्थोऽन्यायोऽत्रप्यतेतकस्येति
दिक् अतुल्यामकारइति यस्मादिमनुकेपदेऽप्येवं कारकवाच्यस्येति कार्ययोगेमायाः प्रतिपदविहितस्वादितिभाव:
सैवेनेति उक्तप्रकारद्वयेत्यर्थ: कर्त्तरीति किंमोहत्यादिकरणमित्यर्थोऽभिप्रायेण प्रश्न: व्यर्थ: स्यादिति कर्मणीत
नेकाभ्याकर्मणिष्ठेव सामन्त्रतिषेधेनेनेतिभाव: परिशेषितेति कर्मातिरिक्ते निषेधेनकर्मणिपरिशेषितेत्यर्थ: विधि
रस्येति अयमेव प्रयोगस्तेस्यात्र प्रवर्तितं आकृतमात्रं वाभावेनसम्भवमात्रं नपात्रितमिति अनेनाहतं:
लोकेनातहीन्तकर्मणिचेति सत्यस्यभाष्यविरोध: तत्रहि कर्मषष्ठीमात्रेमाच्लिषेधेऽपि स्पावेपथ्यमापादितं आहरिति
अन्यार्थविद्धी तेनाप्याकारकप्रयोगे वा निषेधइति प्रत्याप्ततिलभ्यार्थस्येवमापकम्युचितं प्रतीते त्रिभुवनविधाताभिरिनस्य
तरं सामान्यार्थस्येति तस्यहि रजत्वव्यावृत्यर्थं इतिभाव: मतान्तरेसानुबन्धकानिर्देश: कृतीतिवतस्यप्रष्ठार्थ: क्विहयाक
स्पष्टात्वा घञ्मूलकेन मनस्यादितिभाव: अतस्याकपुरुषात्मत्वर्थयोनतिरक्तइति सत्त्वे भाष्यअकृत्वेनदोष:
कर्मण्यावृत्तिनामत्ययोपहतेपार्थ: प्रतीयतेतामिन्द्वदृष्टी हिंसायामपि हिंसा यदि चेतानान्यपेतितात्पर्यं कृतमेपदानि

ति

व्य:१ ति स्वत्वहितानिविशेषवान्प्रतीयतेनतथामती।बहुव्रीहौ सर्वधनीत्यादिसिद्धीहयाद्यात्सिद्धंस्वरंङीन्बवाणी।त्या
दौ समस्तार्थयोतेननञ्समास:बहुव्रीहिणाहंसंयोगनिषेधस्यसम्प्रयुक्तभाषितत्वनिषेधस्यचनेवाणमात्र सुहृत्तो
गम्येतिप्रत्ययस्यात्तेनास्य।भाष्यप्रयोगाभावाद्विकल्पप्रसंगानारोपौत्यन्यत तु ध्याध्यपवकापशब्दप्रवृत्तौचेत्तमाह
समुदायस्येति तथाचेति इहेहदाधस्समीरणमत्वाद्ययवर्णनमात्रं पाचान्नित्यमितिसम्बन्धेभाष्यलक्षणनिषेधानेष
वैनत्वपातरवे तिलभ्यतेतत्रोपरिष्टात्स्पर्शभविष्यति नाभ्येयंदाततोऽप्यवधिकरत्वस्योक्तत्वाह शिष्याणामनुशासति
मनुपूर्वशब्दस्याभिसापेक्षत्वात्कथंसमासस्तत्राह सर्वमपूर्वस्यभागस्येति प्रधानत्वाच्चेति भवतिचप्रधान
स्यसापेक्षस्यापिवृत्तिरितिभाव: समुदायेति छात्रसमुदायापेक्षव: पूर्वेऽतिवोध: एकदेशिसमासविने
ति लक्षणप्रतिपदोक्तोनां ज्ञापकवाधिनामिभाव: इतिभावइति इत्यमिमान इत्यर्थ: यथा स्वतस्त्वा
श्रपवर्णानाभिधोक्तानांज्ञापकवाधिनामितिभाव: स्वतात्वत्वमस्ताव्यात्तभाष्यरीत्यात्तलक्षणप्रतिपदो
क्तोपरिभाषापानप्रवृत्ति: कर्मधारयेणवसर्वमप्यागसिद्धः तत्रैवार्थवस्तुत्वंपथोतम्लेनीसेधमाणपार राम
षष्ठीसमासतत्रहिप्रयेनभिधानाद्वारणीय: पद्येष्वव: ज्ञापकस्यचनोपयोग: तच्चनपनश्वति

नपुंसकत्वं·शरीरार्द्धहरणमितिवस्य [redacted] समास: ५

एवाप्रसाख्यानमितिरिक्त निर्देशादेवेति न च शब्दपूर्वेलेपिरूपाणामितिवद्नपुंसकोद्वाणामत्वेननतेनङ्गीभय
स्यामिहिमितिवाच्यं पाताविभागापूर्वकमर्धमितिनिर्देशेनतत्वाभवसाशयात्तमिन्नलिङ्गत्वमुपपद्यतेइति सकल
स्वेति निर्देशान्मिति शकल्यानावडेतितिनिर्देशेनेत्यर्थ: समानाधिकरणत्वेनमस्कुमाद्रवातिनस्त्रीलिंगत्वसिद्धं अत एवार्द्ध
तार्थमासालात्तिमित्याह य: प्रयोगाद्भुपपद्यते स्वरवत्वदौ पुल्लिंगइतिभाष्यस्यपूर्वेस्मिन्नितिभाव: अर्धेत्नभा
ष्यानुरोधेमकोशादावपुंसि।तेष्वीन्यस्यत्र दार्थमित्यादोसमांशत्वारोपाभिप्रायेणनिपाम्प्रयोगाद्वशमाक्षेसाधु:ग्राम
मिति तेषांमभिप्रेहानिष्टमितिभाव: ननु पिप्पलीनाबहुत्वाद्द्वहेवक्तमुक्तोनेत्यतआह पारवरिति [redacted]
मूनिशिष्यकोशिति अर्थस्यविशेष्यमपेक्षत्वादित्यर्थ: मामिति सत्वयविनस्कत्वाभावादितिभाव: खंडस
एकशेषेलो मुदायेति [redacted] अपप्राप्तत्वमिति एतमेपकदेशिसमासस्यविधायकत्वमित्यर्थ: ज्ञानावेदव
तिभाव:४ चनतेनस्तत्र्यमित्यर्थ: अर्धपिप्पलीत्यप्पलस्यांशत्वचत्रपार्द्धहराणस्य एकदेशिसमासानाप्यपनेदतिनभा
ष्योपक्रमात स्वस्वाविति तथाचतत्रैवभाष्यमद्दृष्ट्यनस्य पिप्पल्यर्धमितीति प्रयोगरूपेणदृष्ट्वाविधारवेपिप्य
ल्यर्धंचैकदेशिसमासेनमुक्तेषष्ठीसमासोनभवतीतिहिमिप्रभृतेर्धितिमुत्रस्थं भाष्यमेकदेशस्मिन्निति साधु: द्विमासमिति

मि

७

२७०२४० तद्धितेषुपरत्वल्लिंगात्तानिषेधपरत्वाल्लिंगात्तानिषेधकृतोलुक्ग्रहणामत्याख्याने॥ घटोरिवमत्तासत्वान्नंतस्येतिभावः विभक्ती
विति उक्तमित्याकर्मधारयेणाति द्विमाश्चितेत्यर्थः एवंहि तेनभाष्यन्तन्त्रुरुषपदग्रामानंक तिष्यतेनकुरेशियद्ग्रणानिर्देशेहेतु
रेशिम्नोरितिवृत्त्या। मितरेकदेशियद्ग्रहणकेनान्यनकार्यमेकदेशिसमासोनारभ्येतकृष्यमधीमतीति भकारपेरेपस्त्री
लिंगौस्त्वलुक्यीहि शब्देरनभिधानात्समासमासोपि चलत्यर्थाभितिक्रमेधास्मैत्येतदर्थः एकदेशलामिति नचात्रपरेश्र
चहितमासमापन्नस्यामेन्यपदेशः सोचलत्कल्पनस्यतेविकल्प्रशंसतानिष्पिभमानात् नहुमिति पारिच्छेद्य
र्थः नहोरोति तस्मीदिच्छिन्नगमनेक्रियपुरहितुपुरुषस्यपारोछेदतेत्यर्थः तदाह पञ्चहोति पारिच्छिन्नोनेति नामत्का
न्ताती नन्वनाश्रयत्वेनेतिभावः सामानिसुपमानकारति प्रागभिन्नत्वप्रसिद्धस्यार्थे तद्धोरेसपरायस्पत्तस्यासमस्तानपर
प्रतिपाद्यतामदर्शनेन तद्द्यावत्नमितितिभावः यस्यसमासत्वात्पदार्थे रतिहितिविग्रहवाक्यदोषः मासजातोहदष्टत्वा मित्या
देतात्तस्यैवदर्शनकर्मधारिम्भनीतिन्त्वेतानन्यपदार्थप्रधानापिनितिभावः कार्यदतिबोध्यं नात्समसरशीव तत्रवि
शेष्यविशेषणाभावेवैपरीत्येनेकार्याभावारोपात्तदतिभावः आमारमेति जातपरिच्छेदकोऽयमस्तिवाकार्यीमा राम
सपरिच्छे[illegible]दितिवक्तव्यविरूपभावः विरहन्तीति हतिविग्रहेपोः अयातार्थसामाये तद्र्थः अपच्यार्थेवक्तृप्रीहाविम

सैस्याविमरूपेस्यादिसनेनाप्यत्वयः पंचविधे कर्मकरणसंप्रदानापादाना धिकरणाख्ये तत्रग्रामस्योदकं स्यापमि
तिविग्रहेपितत्तः कर्मलाहिनाः सेधात निर्विकारलाहिति तदेशपानान्यासकृशेहे मांवेतिशेषः किंचेति सर्वादी
नीतिसत्त्वेसर्वज्ञत्वात्सोविके कर्मत्वेश तिभाष्यविग्रहमदर्शनात्तदूतिभावः पदर्थरोति सद्देत्तनाहित्यर्थः व्युत्तएवेत्यस्यद
द्वसंमतदत्यनेनान्वयः मार्थान समस्तत्तः एवैराचित्रागावोपस्यात्याहिना अपीति वोधिते विषये वाक्यार्थेतत
घटकपदार्थस्थेतर घटकपदार्थे तस्यदर्शनात् तस्यदेनसंपरत्वात् वाक्यमेवेनेति युसचित्रागावःसंतिसचित्र
गुपदत्वाच्याभवतीत्येवंवाक्यंभेदेनेत्यर्थः कचित्तगुरोति अर्थानो हतिविग्रहपोगुणाप्रधानत्वंसमासमितिप
तद्विवक्षितमितितेदर्थसामान्येमित्यर्थः कचित्तगुरोति अर्थानामहतिवृष्येविषयोवैपरीत्यंत्रिणाप्रधानत्वादि
रूपेहदृष्टमितितदर्थः पत्यर्थः तदाह विग्रहवाक्योनीहेति पोरत्ममाहरोगोरुतामप्रधानम्रपीर्थानांनोकेहतः स
केचिद्विवक्षितः पतत्पाद्धितार्थविग्रहवाक्येतिउ॰तेन्नोकदृश्यप्रातिपद्यप्रधानत्वस्यवैपरीत्यकृतप्रधानत्वेदृश्यत
रतिहरिम्नोकार्थं तद्धितेलपलद्वालाहतिमात्रस्य एवंरहतिसमानार्थकमेवतदर्थेबोधकत्वेनदर्शमानं

लघुशब्द

वाक्यमितिभावः तदेवमवास्यं तत्फ्वेरेन दर्शयति तत्त्वमर्वेनाम्नाम्नलग्गतः मध्यानपूर्वामर्शात्वात्तद्धरेनदर्शितं भवतिविज्ञानां संवं धी
यः सवित्रत्वपरवाच्यस्त्सर्थादृत्ततत्र्प वातहृहतो तिसत्रेभाष्येतस्वेदमिप्रेव सिद्ध्ररेस्त्य र्थमित्यारोकव्ववृतिर्बोद्धेतिशरस्य
मेदहन्ततेनविधिरित्युक्तेशरन्नैदेयष्ठसमाम्यासिद्धयसवार्थाशंबहतीमिप्र वरण्यस्वावेतीयुक्तंतचश्रवमेदाहित्यवहतीति
किंपामाप्यान्यक्ष्मेठतिकर्तृत्पर्वोनमिसर्थः मर्थ्यसमान्यामिद्रस्वायोपद्र्शकेवहतीसत्वाविविशेषरागोविक्षेषभागवेव्यला
मेद्वहनेकर्तेस्वेवाचेत्रपर्थः वर्तमानकालत्वस्याविवक्षितत्वेनभयत्रापूर्यपि षडुः एत च विस्तरेणान्यत्र दर्शितं हेतु
कोहत्मिति तद्धित्वार्थ्यांनरपेदतिविहितेस्यर्थः कार्तिके उत्तरपदेनेति हेतोरतृतीयेतिभावः एकत्वस्येति प्रकारांतर
मप्पंमेवोक्तं नियमसंगानेतिरदं चेकं पटोलुरोधेन पहारांतस्याधारत्वेतरन्नयुद्धारेवतस्य क्रियान्वयरति शोडाद
रात्विक्रियान्वयेनतत्वदारोगतेन्वितास्यापितरन्वयइतिमकारांतरेणापितरमंगसंभवात् द्वंतत्वाभावेन मानसत्वकु
शालरस्तादेतत्सकलाघइतीतेभ्युलन्ये अधेयप्रधानइति अधिशब्दस्याधिकरणमितिस्यर्थः ईश्वप्रधानस्वस्मेष्य
स्वाधिकृतेणोप्रधानइति मध्यगाताधिकरणातत्वत्कि प्रधानइत्सर्थः तहेह मध्यइत्यर्थादिति वनेतरति वनहृति
मध्यभागइतिबोधः अविकारात्वमात्रेति नतुमध्यात्वांगितवदृविरित्यर्थः अग्रंगतीरिति अव्ययीभावनिपत्तेनसंप

एम

स्यापात्तेत्रात्स्भवारिति भावः अप्रथान्त्रतोत्त्रिकार्थइतिनाव्ययीभावसंकारे स्वातिमसंगाचेति चेमतत्रमात्वकृतप्स्या
नुमारिव्यास्थाना तत्राबेहस्रप्पपयहणमितिबोधितं अप्रथाऽप्सधेतिपरोयाजस्माध्येहेत्वंततकयनेनतरमंगातिः स्नेह
व अवयविनइति तदीत्तामध्यगतात्राधारत्वेच चनेत्तापिवनगातावात्तवोवकुत्वेनतस्यतिभावः अधिकरणप्रधानइति
श.क्तिमत्वप्रानइत्यर्थः प्रसंगतमिति विशेषणसमासेनेवगतार्थत्वात्तदाह व्यधिकरणेति एवैतत्प्रकरणस्थाय
कथमर्वतमितिभावः अत्र शोका हुर्लभत्वादिति सप्तम्यपत्सुकेरितिभावः शाकपार्थिवादीनामिति नवकेयुरात्मन
न्यत्वात्वनेशेषः शाकप्रियपार्थिवस्तमाहिवारनात्मनादाहृकेनस्यावसपावरपकूतत्वनैकेयूरोत्तमत्रेत्याख्यानस्यासंगतत्वा
दितिभावस्ताध्वेनपत्वाह पनशोतिनवरसहस्रिणामित्यस्यान्वयपवेकारमपदेनरूविणामित्यर्थइतिभावः पहानवपात्स्प
नवापूपवेकेनलक्षणा प्रसामसामसत्यामानपत्मेषाण्यानस्यावोधकेनेनसमासइतिबोध्यं नवरसामस्यामेव
नेषणमात्रेकविंशामित्यर्थइत्यन्ये भाष्येवेति नत्रेति स्वेविघस्तस्य अववपवाविवायामवाणेतिविग्रहस्पुक्तं ए
कार्यमवात्ति एकदेशप्रापिविषयापिसमासे नेत्रेणोवरागोद्विघनस्यार्थः इहसाधुत्वंलसोत्रत्वात् स्पाद्वेरस्या
देशप्रत्ययपोरितिमत्रेमत्ये विषयसति अत्रमवयोर्व्याकेवारनइस्यादेतंद्विवोत्यातिः अन्यपोतकाणीनामप्रयोगइति

शा०स्त्र० नत्स्यादितिभावः प्रतिपदोक्तत्वादिति निरवकाशत्वाभावेपिप्रतिपदोक्तत्वेनशास्त्रोपस्थितिकृतत्वाप्राप्यमितिभावः
प्राबल्यमित्यर्थ भाष्यग्रन्थमित्यर्थः परस्परसंबन्धाभावादिति निरूप्यमानमात्रयोः परस्परसमानाधिकरणभावाद्यन्वया
नहस्यचार्थःन्वन्यथा पंच धनपरभापरस्परविशेष्यविशेषणभावपूर्वकमेवान्यपदार्थोपसंक्रमाद्धत्रापान्नहप्रियस्य
न्नेसमहत्वेवतद्धयसंक्रमोतस्संगतिः स्पष्टेव वचनसामर्थ्यादिति तस्सामर्थ्याद्धत्तपत्वेसमानाधिकरणपमाश्रितस्येव
र्थःवाधितइति वयाणामेकार्थीभावेइयोर्व्यपेक्षापाद्दुर्लभत्वात् महाविभाषा हि व्योपेक्षावाक्यपक्षेवोवेकेतिभावः
सापकमिद्धिति वचनसामर्थ्यादित्यनतस्य स्वरूपमप्याप्तसिद्धं नित्यतत्पुरुषार्थ स्यवानुवादमात्र मितिभावः ज्ञापकत्वेपोधका
प्र ज्ञापयतीति वार्तिकस्येति तत्पुरुषपदस्यात्र सिद्धार्थानुवादकत्वादेवेत्यर्थः त्रिपदेहिबहुव्रीहौसतीदिशिपदस्यांतरपदत्वा
भावात्पुंवत्वंनस्यात्सवार्तिकस्यापूर्वत्व हि शम्पोत्ते अनेकपदे पूर्वपात्तत्पुरुषपुंवद्भावन्धायस्यैनतपुंवत्वं सिद्धमेवेतिहरदत्तप्रजा
व्यर्थंस्यादितिभावः पूर्वनिपातेति त्रिपदेषुबहुव्रीहौसर्वनाम्नांसंख्यायाः निपातः स्यादितिभावः नचैवपूर्वनिपातस्यव्रत्तपतद्धाश्रप
तामवशेषकत्वेकृत्यंमहत्तार्थमाध्यकत्वेनास्यैवपरस्याव्यभावसहतिवाच्यं तत्परस्याहितिर्देशोत्तत्पूर्वनिपातस्यानित्यत्वेनापि राम
नात्वाद्दिरितिपुंवत्वमवस्थंफलमित्याशयात् कर्मधारयपूर्वपदस्केवहुव्रीहोतस्य विशेषणत्वेनपूर्वनिपातापत्तेः समनकृतः

सत्रार्थानुवादकत्वेतिनात्तत्वमिति दिक्संख्ययोरभावात् व्यातभेद्विति ज्ञापकमिद्धार्थानुवादत्वात्सवर्थः अनगचाविचारत्वेपुंवत्त्वापत्ति
रितिभावः ननुभोत्तपूर्वकसामानाधिकरण्यमाहायद्वित्रपूर्वकोनेकेत्यपिदर्शनमत्तआह पूर्वकालैकेति तस्सामार्थ्यात्मकृत्वा
घत्वममद्दोभावाभावइतिभावः दिग्गितिदिग्गयेत्तपदिस्यांसामानाधिकरण्यमात्रनियामकंनतुविवृप्पातयोरेवेत्याह ः शन्देमेका
र्थीभावेत्रवपेक्षितनत्वनिष्ठ्ययेत्याह ः आवश्यपेनविधिरितिसत्रेसाप्येसमपदस्तोपमात्मविहितनत्वस्यापरमार्थ्यस्यामि
द्धिः ययोज्ञनकनकिंचैवंमाचीयाओत्रिपायस्याकसमानामिपरस्तोरोमामानाधिकरणनिवधनस्वत्वात्सिद्धिः तंत्स्येमध्याकथंवि
त्सामानाधिकरणनिमित्तंकर्मधारयोत्तुनित्यव्यपेक्षभावभावात् तथाकार्यवक्तितादृहनियामिकानतत्तन्मात्रवृत्तिता न्त्र
त्तिमसंगोत्वेनाभिधानोहमतीयः अतोस्वसाध्यसंपत्तिवचनमेवमत्यारव्यातेमित्स्वाततेहामत्तेतस्मयोगेन्नति वृत्तावेत्यपिय
इति स्वरूपेवागेहयहो ः सामानाधिकरणपेभावेयिभिपधारेनतयोः समानाधिकरणपादहत्त्वोहिर्निरोधः पर्वतनेजैमिनीये वा
धुल्लसोमहत्वामाध्यायेपेण्यः सुरुहस्वाणेहलस्येन्तःतत्राह ः कर्मधारयेतरद्वहहेरूपेवेराज्ञाडीक्तरोस्वत्वा निसामानि
गर्वामपेभेहण्डः पञ्चहस्तयादिरवाक्य पूर्वकालेति वृहदद्यं तरेसामनीति प्रयोगस्यार्थः नेहहंतरमिति किंतु त्रिपदबहुव्रीहिर्वि सम्यकः
तोरविशेषस्येति त्रिपदबहुव्रीहेःपत्वयसमकतिसांगहेसमरवारः उत्तरपदेपरेतादृद्दत्वसतिशिष्टहंतरेणाहह इयंततोस्तीत्वा

लघुशब्दः

सत्त्वमिति तस्योविशेषः स्वविशेषण्यस्य प्रवृत्तिरितितत्पर्यं तत्रैवशेषभाष्येस्पष्टं तत्रैवहेतुमाह निलत्वेति वाहेतौ संकोचे समासो
नमान्यत्वविशेषणविषयत्वे नन्वानन्वयेष्पर्वपदस्वरूपः स्वपदार्थः स्वार्थयोरन्यतरस्यातिरेको भिन्नैकमित्तत्वाभिन्नमितरेतिहेतु
त्वात्सिद्धान्तेस्यातिरस्तिवाच्यं पञ्चहापेक्षस्वपदयोगोनमन्यदेयवाय्यस्यासतरेभावः पद्धात्वेन विरहः स्यपतनेनकेपदितिभाष्ये
तनेपिमासंघतत्ते त्वाम्यांजपितव्यमितिवत् पविलक्ष्मीबाह्वस्तरस्वरस्यवक्ष्यहस्थेनरमामेलत्वेनकृतेतत्र शब्दास्यात्त्रिपदस्व
डत्वोहोदृढानेतिकस्य वृत्तावाच्यातिर्भावेरोकार्य्यभावात्रहाहिवृद्धस्येनियतत्वान्तिकसमत्वापद्यात्वत्रनतेभावेत्वाकार्यो
भावस्तत्रहाहृत्वास्येत्रिपदेनिर्वाशेषेवृत्तस्य स्तोनभवतीति तत्र्वहिकस्यस्पसंज्ञायामिति समासेनद्विगुत्वाभावादिति
भावः एवमवेति पदीनियातोर्थः शब्दमेवतिविमितेति वैयाकरणानांशब्दार्थः पपाणकेति अत्रापि समवेकृतसिलशब्दः
कृतपमानपरः अत्रव सर्वपदस्यसरशब्दाहशाकत्वादेव नतृदृर्शनीयापामाताहृर्श्यनीयामातेसत्रापिद्वपमेकते
पकमतीतिजनकत्वेनसामानाधिकरणोपपत्तिरुपपत्तिः इतोहृतेः शाकत्वसामानाधिकरण्यपवतेतिहेतेरवस्य घातकत्वा
त्वमेतेः शाणपितामात्वाधिकरणपमतेतिवोध्य मतप्रवाभत्वेति घवेनतन्यः स्यामहितिवाकेतत्कृतार्थस्यमाहस्यम
तियोगितेनन्वयाद्दुपमानत्वमसीतिभावः उपमेयपरत्वमिति तत्त्वश्यामादिशब्दानां स्पष्टमेव अत्रमन्त्रत्त्वकायतरस्ये

विशेषेणाक्त नत्वमध्यमनमुपसर्जनमितिमहासंज्ञाप्रातेकस्यमध्यमामिदिष्टस्येसप्रधानस्यैवसंज्ञानमथानस्यैतिवोधः पि
तेस्यवेनेनत्वत्वयावाम्यकस्यैतत्त्वास्मानिपामकृतेस्यरुचेशाह पदेति सविशेषणेनेति विषयतानिशेषमेकारतावदित्यर्थः।
तत्रैवहिलोकस्यविशेषणत्वेनसिद्धं नतुहृत्वाग्गुणसमभिव्याहारेकत्वमावत्वमत्राह रूढिविषयतापदशविषयताकत्व
मित्यर्थः अत्रवलायतेइति गुणोहेवत्ताहृशविषयतेवत्वंनिश्चीयतेत्यर्थः रकेनेति अमेनस्त्रिलायाशिलीविनरकशिल्पा
जीविनः कृतोस्तुहोहृत्यार्थः अस्यमहत्त्वेपामम हेतोः कताइतिष्णा गुणाकिपेति मसाहकसञ्चकरतारो रूढिवाद
ति तेवृमतान्वितिकामसत्वार्थकामकोडम्बहृतेहीत्वजैा मत्तमलवाचकामकनीतिकोशप्रसिद्धमतोन्विकारयः न्यायमिति
नव्यपुर्वेतित्वस्याप्योपुरासमितानाधिकरणं उभयारोपोपेक्षयात्वत्वियान्सोसारापीभाषात्तापनस्येवोविसात् पर्वो
तम्महतोति पर्वतिलवपम्यग्रहणात्पर्थः इकिमयेयपाठः सर्वनिपातेविशेषइति गुणावचनत्वाहुमिरागोशरस्यापर्वनिपा
तइतिभावः उपमानमपशब्देनेति त्वसनाप्रतिपहोक्तपाशिमोपयेतिभावः इदं चमतंकेपथस्पष्टं किपापरवाय्येपस्ते
सर्थ्येभिन्नत्वाविति प्रवृत्तपदार्थमथानस्यार्थं विसेति तेनत्वाभ्यांविग्रहोन अन्यपदार्थेति स्पष्टवेदभाष्ये श्यामपितत्वेन
त्वाविस्येतेरति अरोपितत्वात्सगत्वगमान्तरपदमवतितिभिरमिमात्त्वोशत्यजनत्वाद्योस्परत्यर्थः हवमत्रापियोध्यं स

११

त०श०२ तदेव भाष्यसंमतं नञो वाचकत्वेनाह आरोपमात्रेणेति इदंमत्र वाच्यमेवोत्तरपदार्थे विशेषणं तदाह विषयत्वं
तेषु तस्य गत इति तादात्म्यारोपश्चात्र नामार्थयोरभेदान्वयव्युत्पत्तिस्तु निपातातिरिक्तविषयेति भावः यतश्चात्र प्र
पक्षे घातकत्वेन नञ इतितत्र समभिव्याहृतपदस्य शक्या घटादौ एकत्वविशिष्टस्यैव तत्त्वं किं विषयत्वेऽप्युपास्थि
त्यभावेन विषयत्वं तस्य संगतेस्त्वयोः संगतेः एवमुपास्थितयोर्हि संबन्धो भवतीत्याह आरोपितेत्यादि इति
स्वरूपमित्येव बोधाकारः आद्ये तत्त्वारोपितेत्वारोपितत्वानितिप्रदर्शनीयं अवयवमेव एवं न त्वेतं तेन नञर्थत्वे विशे
षादिपुरुषान्तरसंबन्धेनारोपितत्वादिर्भवतीत्याह किं पुनरारोपितत्वान्वयस्य हुर्घटत्वात् एवं च नञ्समभिव्याहारादर्थ
स्याः शब्दार्थसंबन्धस्यानिरूपितत्वे समस्तेन तस्य अन्यसंबन्धेनाप्यारोपितत्वं तत्र वारोपितत्वं संबन्धेनारोपितत्वं नोपितत्वं
युक्तात् नञोत्तरस्य विशिष्टस्य तत्रैकत्वानोपयनिर्णायकः इदमेव नञो द्योतकत्वे नामार्थयोरेकार्थीभावस्य सहारो
पि विशिष्टानुपमायोग्यत्वान्न भवेदित्येतद्वक्तव्यं किं तु विशिष्टस्यार्थं वस्तु सामान्यविधायकशास्त्राद्वेत्याह एवमन्य
कल्प्यमानो विधिः मनुष्यतीसादौ एवं नञादिव्यवस्थायां तत्र अन्यथा तत्त्वकल्पनात्तल्लोकस्यात्र तत्राऽपि विशिष्टस्ये
वबोधः स्वपदशक्तिबोधनद्वारा विशिष्टस्य संभवादिति भावः आतस्योत्तरपदार्थप्राधान्येऽपि इति विशिनष्टीति अ रम

न्यथोपसर्जनत्वाद्द्वान्यपतेतेः हल्ड्याब्भ्य इति लोपस्याभावे तेन तदेव पश्यस्यैवमेव नञ्वचनसामर्थ्याद् हल्ड्यादिलोपप्रसङ्गः उपस
र्जनत्वेऽपि नाविमितिवाच्य लाघवेनोत्तरपदार्थप्राधान्यस्यैव युक्तत्वात् अर्थिकार्थमिति आरोपितत्वबोधोत्तरं
प्रकरणादिना तत्त्व [illegible] ग्राहकत्वरूपस्यान्तःस्फुटबोध इति भावः उत्तरपदार्थप्राधान्यं मन्यामहे इत्यनेन कैयटाद्युपपा
दितान्यपदार्थप्राधान्यपक्षस्य तदसम्मतत्वमुक्तं बोधितं तेन अन्यपदार्थत्वेति नानावाद इति नन्वेकत्वादेराहृत्य विषये
आरोपेण तस्यान्वयेनोत्तरसंख्यापायाद्वयवत्संख्याव्यवहारोऽप्रतिबन्धकत्वात्तत्र बहुत्वे मा शङ्कनेकत्वस्यैवापाद्यते स्वस्य
न्याये नैकस्यापदार्थस्य उपपत्तिः तावदेकवचनादिनाप्रतीतिरित्येवाह यद्विति यथोऽजादेरल्पलक्षणान्तापकस्य
हत्यादि अनेकत्वस्यापद्यमेदेनाभयविशेषणत्वात् सोऽस्य इत्यादिति तदुक्तमसमर्थः कारिकायां महाशारीनातिपा
दर्शनात् तत्त्वेनैकोपेति तदुक्तमपि पदे तेषामार्थिकोऽर्थत्वकथनात् आकारविरुद्धं चेति विशिष्टस्य न तस्य माधा
न्यापि स्त्राकरोत्कान्तरपदार्थप्राधान्यस्येति भावः मामजातवदिति तत्र यथा प्राणस्य प्राधान्यं तथा प्रकृतेऽपि
तादरोहितो ब्राह्मणो इति बोधात् नञर्थप्रावेऽस्ति नञर्थप्रकारोपजनितबोधे तस्य समस्तपदस्य ब्राह्मणादेः शास्त्रिनस्त
कमित्यर्थः तस्य व्याख्यानाद्भाष्यविरुद्धमिति तथाप्रकारस्यभाष्येऽनुक्ते अर्थस्य बलदोषसंभवेन स्वपापार्थकारस्य

लघुशब्दरत्न

समर्थापिलमिति मीमांसकाधुलसर्वपदार्थप्राधान्यमिति शेषः नस्योगोवेति नेत्रोभेरवतसर्थेस्तस्यार्थः इत्समपलस्सांगो नि
पातानामनेकार्थत्वादिस्यस्यापि ज्ञापकादिति नञ्समासेउत्तरपदेर्थप्राधान्येमतिपदार्थतितत्सर्वपदार्थप्राधान्ये
पीतिसामान्यापेक्षज्ञापकाइनेकमिमारावक्तवचनस्यापिसिद्धिरितिभावः एवमाश्रयेणतिगोरथंवाघत्राइत्सपदार्थ
प्रधान्यज्ञापकत्वमेवोचितं एतदेववक्ष्यनपलोकयविहितिपरतदंसमर्थनविचारोचितमगिप्रोक्तोतदहुर्थस्येतिन्न
तत्रोत्तरपदस्येतदर्थनास्तीतिकत्वेनात्हृशेष्यकेवोध्येचोपसर्जनत्वेसमर्थेनात्वसम्भवेनोत्तरविसिद्धयेत्ताप्रकोपन्यासमेव
फलोपपतेःत्वासेतिकत्तामप्रोणपसर्जनत्वानोभ्यादिशिष्टस्यत्वाच्चातितत्वेनत्तरपदप्राधान्यमितितद्युक्तिविशेषादि
त्यहनमिदंमोध्यनेत्यमेतन्वह उपपत्ति नस्येत्यर्थः एवंसमर्थनेप्यत्रप्राधुलमेवकमनिंत्रयंसमासेसर्वशब्दानामा
धुलस्यसर्वसमत्तेत्वादितिवोध्यं वहन्निविचारविनामपीक्कादितिभावः एतदाते एतीव यासितंततोध्वनयतोसन्वपः
समोधनोते स्त्रोवनपहृदयवत्क्रियायविशेषणाणामितिहयुक्तिःप्रमाणो कर्तव्याद्योःक्रियायोगान्नेतदिद्ध्यानात का
रकंकर्त्रादियुद्धक्रियाजनकस्यैवकारकोविकारेणकर्त्रादिसंज्ञाविधानात् प्रथमावतिःतेनतस्याक्रियायांहितिविहि
तः अवसमत्तनत्र प्रत्यप्रतिपथायकार्त्तिशेषः चततवप्रसमप्रविषेधेः समर्थसमासइतितच्चभाष्याकृत एतत्

असमस्तनत्रः क्रियान्वयित्वं वचनपुरुषव्यस्येतिघराभावोत्यहभावइत्यर्थेएकवचनप्रथमपुरुषयोरेवाप
तितितिभावः अन्यथा घयभावेवोधे वचनेपुरुषोपवस्यावदित्यमपिद्याणामत्यर्थः कारकविशिष्टक्रियायाइति भतत्वे
घटेनास्तीत्यादौघटत्वाधिकरणताकोघटकर्तृकसत्ताभावइतिवोधइतिभावः पूर्वपदार्थप्राधान्यइति असंहितमित्य
समंहितोभावइत्यर्थादि असंदेहार्थत्वंगौपितमेदेह्योविष्यपदेत्यभिमानः प्रागप्रापिकेरीत्यत्वनेमाहविकस्मवित
तद्यं जेहितानप्यवेदत्यमिद्धिमते क्रमेयवसाधिति भावः पदित्योपतः मस्देहसमस्तगौच्चापितवपलाध्विसमस्तगाइति
कोधेतेऽस्याअवतोनफलतिसंमसिद्धेकार्थोभावादिनेऽस्यस्तहामापदेशेयिकरीतिःसाध्वेव न्यायलिंदेएववलिंगादर्शनभ
लोक्तमितितत्व अभावासाम्यइति अत्यतेभावत्वादिनावोधेविषयोःभावत्वेनवोधविषयेत्वेसामान्यमितितेषा
मभिमानः अव्ययीभावइति तत्रात्यत्ताभावत्वेनैववोधोऽत्रइतिभावः नपादेनेतिनिषेधार्थनाशब्देनेत्यविरोधे
देयवेति अत्रनत्रानशब्देनेवकधारयसमासलनोधाप्रकारेणनेकसेरव्यस्यापातितेः एकमकारमेवान्वयोनमभवा
च्च एवमेवानेकाराहवहत्रुत्रीतिविशिष्टमहस्वनोमपद्येःनेकरूपइत्यर्थेनेकदादेसमरूपस्यवधिहुव्रीहिवोध्यः

ल:सु:१०

गतिसंज्ञा विकल्पइति तत्फलं समासविकल्पः कृञर्थमिति गतिर्बुतेत्यत्र धात्वोर्गेरिति धातोः प्रागेव प्रवृत्तेः एकमकारेरेव
योगस्यादिति भावः प्रयोगानिपूर्वेति गत्युपसर्गसंज्ञे धातोः प्रागेव प्रयोक्तव्या इति नियमार्थः संज्ञानियमेति व्याप्तेः प्राक्प्रयु
क्तानामेवात्तादिसंज्ञानां नियमार्थमितितदर्थः स्वपमेवपरत्वेऽकमन्त्यवादिभाष्य स्याद् प्रयोगैग्राद्यत्वेति
त्वकेयपाणचारमित्यर्थः स्वछापाइति अभिन्ननाशातिशायः एतेनेति पुरइतिकोतत्केत्स्येनना नेति तत्र
वनेत्रिपावावकृत्व तत्सेत्यत्स्तमीपत्तित्येपूर्ति भावः सेतानिप्तमप्रत्येल शेषोवनेतिभावः माधवराति
विभाषितिमत्वेत धातुविप्तयानिवृत्या पितलिहितिस्पन्ये इहेति तेननिवचनेन कृत्वेति सिद्ध गतार्थवृत्तिमा
समुदायस्येतिभावः सवत्तेतिलिपृत्तक्षरांत्वीप्रत्ययोत्यते: मागित्यपिवोध्य स्वत्वतेतरजि उपरं
जस्तत्प्रान्त्यपरभावाद्धितो भावाभावत्वेति भावः अपरमिति महोस तपासवतस्यैवोपपदत्वात् स्वात
एवेति उपपदात्तृत्वलस्पनेतरस्यैवतेन समासाइवेत्यर्थः व्याप्यैरिति व्याप्तौ मेधौ विशब्दस्य प्रशब्देन मरते
नोप्रशब्देन गतिसमासः इति कृञ्चित्तत्क्वातिसमासेनसिद्धत्वात्तत्रोपपदसंज्ञापाप्रयुक्ताभावेनाभावा राम
त् स्वतएव कृत्समासाः गति समित्वेनुपपदत्वनाप्रबुवहृत्तोभाष्ये व्याप्यौकेमगपरशब्देनतरतेनव्याति

१३

समासतरत्यस्यार्थः कथेमेति अधिकरणस्यकरणत्वविवक्षापरत्वे पानवक्तारकत्वा सिद्धं कारक
पालेप्युपपदत्वात्माप्तपाटपदसमासस्यैवप्रवृत्तेः उपपदमिति तिमहासंज्ञामाश्रित्यप्रथमातस्य ति
वृत्तिरुच्यते उत्तरस्मान्निश्चित्य समाधः तदाष्यपणो: वृत्तत्रिवर्णोपिसमुद्काव्लवेसोऽप्रयोगात्वात् नो
सारस्याह तथामतौ सोऽदिन्यादिसेति गतिरितिसत्रेपितद्समंबंधे पं होषु: एवनिगतः संपतेतिव
मल्प्रत्नविति हविस्वेततस्यैवंधेमे सतव्यावेता वृत्तिः पदस्यवयष्ठ्यांपतेरिस्माभिमनात् शावृत्ते
नेति भाष्ये कृतेतिशेषः कृणविति संहितायोनित्यत्वादितिभावः हिगिति हितार्थलपदस्य वि
शेषस्यधात्वाहाक्कोत्रजतोस्यव्यावृत्ति सिद्धावृत्तिः ग्रह गामेवोगुपोनिवृत्तोज्ञापकं महासंज्ञाक
रणाद्य राज्ञत्र्यात्यादेशतदोषः अतस्व पराविस्मादीनांनोपपदत्व एवानाहारकत्स्यादोषत् क्रि
पाषोपपदस्येतिकार्यार्थमुपपदसंज्ञावेत्यकार्वेत्तत्रास्यप्रवृत्तिर्वसर्वेतद्भावतत्र्ये चनितंवेद
भाष्ये तदाक्तुत्तमपार्निवृत्तिः अतिङ्· तत्स्वस्य स्यातिङ् ताघटितसस्यर्थ एकंकोपपदमतिव्योचक्षाणा

हपु॰ले॰ १५

स्यामवर्तस्यमर्षयोरिति सत्रस्यभाष्यविरोधोदृष्टव्या मिति निपमातमभौवेति ञ्चामेचेतिनिपमत्वपावर्तं ख्येस्य
र्थः ञ्चमेपतत्स्यविधानेपदुपपदेतत्स्यपेन समासेतत्स्यन्ते नतस्य विधानेनेत्विं चन व्यक्तेरिभावो नात सत्वेप
रति नहस्तत्स्याहताहत्योहोवापोज्यस्तिञ्चमित व्यमिति भाव तस्येति उपपदमितिसर्थः ञ्चपेमोत मिति
ञ्चव्रविभाषाग्रेप्रथेमेतिसत्रेणा कागविविधानाचस्यामेवतु न्यवेधानतान्यग्रे मल्लसत्रहाव्यमतेनसमा
सामावान्नतस्यनिपमविषयतेतिभावः उत्तरपूर्वमकेतिसत्रस्ति उत्तरपदमापुरुत्तत्वतिसर्थस्तरार
श्चाहितामस्तीति ञ्चना भाष्याभ्यो मितित्वा नुवर्ततेरविमतेरर यद्यपिलिङ्गमपम्ल लपपात्राविशेषः
श्चाहिताम्नीतित्वेनकाजर्थेन त्यापिन्यभावनाभिलोनतूमभावपरेपरत्वाहिरन्याहिरन्यापप्यमिति
भावः श्चितोत्यनेनाचीरसमार्थे व्यक्ता तनितिति विर्स्वरोत्पातिपातलितिसह सराहिधिति समासांतापेऽस्तु
ति तत्यस्य प्रसमासत्यातावयय इत्सर्थः समासमारङ्गु तिस सेमतासेतित्मपपूर्वीकृत्योप्यं इपमचरति॥
ॐ पेमत्वेदृदं प्रमाणोत्वेतु मात्रचोत्नुगीवोभ्यं न्यवेयकारणेविरोधेः तेऽत्राह हेमंतत्रि चोदितो पतोदे १८
इदृशानमतमोत्तप्यन्नाप्याइत्सर्थः स्यघचेदृहार्थतनाप्यतोक्त स्कृवङ्गावा।शिति समाहारोद्वन्द्व

रित्सर्थः ञ्चाकोरेति प्रहिताममेवत्तवोहाहरणाहिस्मर्थः स्यत्रादृहाहतित्पुलिमोतेऽत्राह संख्यापर्वमिति स्व
प्यदृतिश्वेतनहारणामाह ञ्चहस्वेति स्त्रिताहिति ञ्चहृस्वेति निपमेतदेयपर्यमस्थमेव निपमफलेनेताद्
कमितिञ्चहानिवत्तनित्सर्थकालादिसनुशेतोनेन निद्वनमितिरव ञ्चसंभवदि यद्यपिञ्चपत्योः हृदमावेप
वीभतमहतित्यर्थ पञ्चीसमासः तेमवेतित्पापञ्चमतेऽः हृः संवक्ते शतत्यातपुरापर्वतत्स्यान्नहस्वसिद्धेत्
तेप्पसस्ततोन्नत्र अवहितानामहः शाहम्मिन्न नामेवपहाणाहत्या दिमामा गापहिश्रिवो ध्यं ञ्चसभवाहित्यप्पसते
प्यस्त्यस्यति सम्भवाहित्यस्रोरार्थः फकाणेति तन्नेश्चपमसम्याविपरिणामरविभान्नः तानर्थेति ञ्चत्रन
षाकालेन त्यत्पाहच सचविधानानुरविभाव ःकेऽचिद्विते शक्लोऽनुपायसामाकत्याप्तन्वपित्ता संभवेद्
तिभावः पत्वेह्रीदृशो भूमोन्तरुस्तमासा न सेवेवच विभक्तिविपरिणामेन कार्यमिति तन्मपत्नपचाइत्सप
तावसहस्याहावतोहातत्कनोनः रचितोतत्समासव्यवहारो तत्सेश्मिति ध्वनेह भाष्येत्विति ञ्चचमावहानि
ञ्चरतत्स्य प्रकृत्तमवृत्तवस्यवानि कस्यमसाव्यानापभाष्यकृतमसर्थः होयाहीति वाहुहिपुञ्चहनरतिपाठहुप
रजीवतेपिरेऽप्र ञ्चपुरुषमिति कालावृत्तत्त्पवाइत्लादितिभाव प्रामादिकत्वाहिति तदप्रकारस्पष्टत्र:

मासेतिमिभावः लुकेति स्वतस्तकथनमेतत् अगेकारइति सर्ववर्णापाथान्तान्त मसपूर्वसत्वानितिभावः द्वि
निष्केति नचांद्विविस्तेसन विलाहिम्मेतिषुवेनसेबुमावृनोनल ककोःकाराभावात् तथाचत्रोस्वकोसपसंगते निष्के
सान्मेसत्वे त्राहंगरगापुंछेति ठकअनुतिन्वारितिवाच्यं निष्कसारउन्मानवाचीविस्तारपः पारेमाणाविशेषात्वेति
मनमन्नप्रस्तहेतुत्तारिभिाकेतत्थाजेविलारापात्तत्त हस्तिस्त्रपरिमाणनत्त्वाद्विगोरिकिंपिनिविक्षेपिरह
केत्वानाममपानोरीत्येवागात्तरठत्रहत्यसपत्तरपगृहठकरत्यत्रोस्य व्यःप्तेनेद्विविस्तस्पविद्याते नेवेतमसरिमाणा
निषेधोवर्ज्यःस्यात्तत्लामर्थ्येतेतहमावकरम्नापेक्षपात्मपारिहिक्तरीत्यवत्तदानासविनलाप् तेनापितरर्थेवी
धस्यैवोविस्तात् तांजत्येति तहेतोश्चेत्यत्यर्थःउरहत्वमिति अनुपसर्जनादिति अवार्तिककारीतिनिरस्तः चत्वर्थः
द्विगोरिविहितविलवस्थःनत्तुबहुहिरिमगाउहत्तपारपाठहेधांहैंस्यारावेत्तुपसर्जनादिति वार्त्तिकमुपपाद्यति स्या
देतदित्यादिना स्त्रीत्वमेवबपाति पञ्चोहाहानलेस्यरात्राहराश्चयानितसमासमात्राश्चर्यंनिमितलिंगस्यान्तरं तस्यस्ते
वीविकास्यचवाधेनापयन्तीवहिर्भूतत्वहितार्थनिमित्तलिंगबाधकत्वेमानाभावइतिभावः पुरस्तादिति अनु रामः
हातत्स्यपेत्तपातद्विता येहिगुतिसस्यापरत्वादिनिभावतदाह तथाचेति केनापामुक्तो तत्र्वेस्पुसाहे

स्यनेषह्नेनेति अमेनस्त्रीत्वमेवन्नासीतिसूचितं तथाहि एत्वाहूहाइसनेनवहिर्भूतत्वहितार्थेनिमित्तलिंगाबा
धकत्वन्नेउपस्थितेराबाहहाहारगान्नार्थस्यविशेष्यत्वन्नपुंसकमापिकेलिंगमेवबाधः स्यान्नतुबहिर्भूतत्वमाहारविशे
षमेपुंसकमाधिकस्यापिश्वलोत्त्रात्तराण्यापाणामिः किंतुम्राणत्वामेसाहिवाकस्मार्थिकोपेपरत्वात्तेनाप्यहाहारि
विषयेपुंस्त्ववोध्यापत्योपुरवात्स्त्रियोतिसूचेककेदिपिग्रहेणांकत्वाभाष्यकृतासस्पद्विगुमास्त्रेजितोतिकमत्याख्यानस्य
संगत्यापातेः नचहाचाहेत्ताहिवनार्थत्तस्यावश्यकत्वात नचेदमप्यकृतेशिसमासविषयकमेव अहस्तस्यारगास्य
पुरापूर्वदिनास्यापिसार्हैवेयध्यापत्तेश्च सर्वाह्नस्याधातिध्यापत्तेश्च एवंचोत्तरागस्यपरत्वात्स्त्रीगास्याद्विगोविल्वा
दिनिषेधेततविषयेत्तहपवादस्याप्यप्रवृत्तिरितिनिनोभोत्तं अहरादिकोतगात्रिरित्यर्थेसमासस्यस्त्रीलिंगत्वस्त्रि
गास्याद्विविस्तारिनिषेधेनत्तविषयेतहपवादस्याप्यप्रवृत्तिरितिनिरस्तं अहरादिकोनत्वादिसहितार्थेद्विगुरी
तिकोशश्च हाहान्तावेतितिविक्तविषयेवस्याप्यप्रवृत्तिरितिरिक्तं द्वेअहनीयस्याभिति बहुव्रीहौगताहारहस्यस्यानो
मरितिभावः बहुहारिवहः रवपाठाद्दुपसर्जनत्वेपिडीपू संहेतस्यापीति तेनपरममहाबाहुः सिद्धः अपागीनी
पत्ताहेति चामाहिप्रमहत्त्वेवोत्त्वपत्त्वपोवार्तिकचालोकेरितिभावः अकाहतरस्तेचलिाविशिष्टपरिभाषाभा

१६

ला०रा०२० मसख्यापुमानितिपरिहितमत्रेभाष्यकृतात्वेनपुंवद्भावात्सरस्वाहात्वमितिन्नशंक्यं अचिरमसाशिति अहोयमपन्ये
वतेनन्तुकोप्रि धानादिति भावः इद्देनेति राज्ञन्यवहुवचनईहरत्वनुवर्त्तमाने संख्यासनेनपक्षेपदस्प्रतिवारस्पत
त्रमांत्वेसत्यर्थः मृकमणादिति मकमोहित्यर्थः मकुरादिति पाक्त् धामादिकमेवति समाहाराद्विगाविमर्थः
संख्यापूर्वात्रमित्यस्याम सवृत्ति चिन्ताघटोनुरोधेन समाहारशब्दगोकवचनते: भविष्यतिमपारेतिमत्रमव्येविश
झ्रजेपंचदशात्रशति मपीगोलत्रिंशान्पंचदेशोगोत्रपोपास्मिन्निति बहुव्रीहिरवमत्वन्नेवेतिपागविभागात्स
मासांतोवोध्यः पोनत्वेपरिहाषाणाह तद्दिनेशहइति तद्दिनाद्दीति प्रशस्ता॥ तिर्यर्थः पकृतेरिति परि
हात्मनेपाठेक्ष्वपिपठितेतदतिमतेनेदं माध्यवेनंप्रागुक्तमिति अत्रेतु विंशीजेवत्ते विचपथदत्यास्यपालि
गतोपवादेरत्वात्सरूपेमवति तत्रैवमहतोयापेवोदत्वेमित्यन्नोन्यत्रयोप्युत्रवोध्यः तस्माद्धिपथाः मिपथ
ताद्देत्रोकाप्रपला ..मस्यानिरामशिष्यमितिन्यायेनसिद्धमितिवोध्य हिताधाति क्रियाविशेषणादितिशे
षः स्याविद्योमनेति तदभिन्नेन पानेन स्वभावपपरेतित्वबोधात् नस्तिधारेति तेषाचात्वर्थत्वविवक्षायेसर्थः राम०
ज्योतिषामाभिन्नयागकरणिकामिष्टविषयाभावनांपपरेदितिबोधस्तत्वभिमाने:तथाबोधानन्तुभवेनाह।

अन्यथेति पुंलिंगेवेति आदिशदसनितसपुंस्त्वात् अतएवप्रातरादिरित्यत्रप्रातरित्यव्ययमृच्छीवंबनेः।लिं
गत्वेपिवाच्यादिस्यमुपस्थमेव॥ ॥इतितत्पुरुषः॥ ।तत्त्वमप्यमाविभक्त्यार्थेस्तत्तुचितं अस्यपदार्थे इतिमत्वा
तमरंचात्र वृत्तमिस्त्त आह अनेकमिति तत्रचविभक्तार्थासिप्रमवेध्यतभोवेराप्येकार्थीभावांगीकृपान्नचित्रगुरि
षरनइत्यादौ मामाना विकरणप्रत्यपपत्तिरिन्यन्यच्चविस्तरः तस्यापि समासस्यापीति अथमनेकेति कर्मग्राममध्येस्य
इये: सर्वोवोधेसांतेभ्ना विकारणाभावात्समाह: प्राप्तमापन्नस्यादौ पवत्वचकस्यमितिविंदं भिन्नेति मस्यपार्थस्य
होसथ्यमिति विशेषणातीविषयेवीत्यर्थः मत्वेति तस्माद्विशेषणीभूतेकर्तरितत्याभेदान्वयदत्तिवृत्तत्त्वंतरमूर्णीका
यं बहुनामिति सामान्येमोक्तमर्थविशेषतोविशेषाणाति चकारेति आदिनाक्रोतानुवर्थसंग्रहतत्पानिवेशाभा
वत्तत्त्वेवोध्र्यवंलोपवचनंनकार्यमित्यर्थः बहुकत्वानीति अस्यपार्थेप्राधान्यादित्युत्पत्तीत्यर्थः कर्तव्यमिति इहमु
पत्नेत्याविभाषाविकारादीनामपिन्यत्रविस्तरः समासेनाभिहितत्वादिति एवंचतेषाकर्मत्वादिरूपेतेवुनातित
भक्तिवाच्यतावच्छेदकरूपेणाकर्मादीनाकर्मादिशब्देरिवैत्तेयस्यानभिधानादितिभावः तासिद्धेरिति अत्रवकाप्र
लेनाव्ययीभावादिसंज्ञयाअप्याघाधादिति भावः इत्यनकाप्तीति मुख्यार्थेत्तनसमासेनाभिधानादितिभावः ववना

१६

लघु०

ंभमवत्स्यापान् नतिथेरिति ज्ञातेश्चेति निषेधः अनेनानुनिषेधेऽप्येवं पुंवत्त्वं न धारयेतत्स्य प्रकृतेः किंच
तत्रत्तातिषिपुंवमी निर्देशात् ततः परोपमत्स्यपतत्वेनेत्सानिषेधो नायत्वथा सर्वचमस्त्रिधानेवहुव्रीहाव
पिरेऽविश्भापेरस्येव नाप्यतत्रस्योरहत्मोलग्नचाप्यपस्थितार्थदृशिनयन्नेवविपत्नेरुविडस्यान्तेरापन्नेते
भाष्यमतेज्ञातित्वाभावाच्च माष्यामनुत्पाधेतेति नद्यनुतोवेत्तज्ञामनुस्कार्थके भाषितपुंस्कादित्यस्याप
मित्रहत्वं पच्यतपादिति अनऊः समानाधिकरणे इत्यनुवृत्तेः भाषितपुंस्कास्यपामिति महाति निमित्त
स्याधानाद्विवक्षापासमी सत्तमपोवा पाक्रिमवेनाति प्रमाभामिलोसतिपुत्रास्माषितेभवतीत्यर्थः
स्त्रीपत्नूपेति स्वेरितत्वमतित्तयामाभावाद्विमर्षः श्वेवः पराश्चिमिन्वनिति उमारपश्च परत्वविपि तत्पादेनुउ
तेतिनिभावः पूर्वस्मर्गशेरोषोविति पूर्वशब्दे स्मानुवाराः पाः समासान्तं वर्ननस्य च गाहीर्यदृस्यार्थः पूर्वे
सर्वोऽपिस्मपाठः शैर्योऽत्योस्तीतिविधत्तरध्येनवति पर्वपदेनाक्षिप्यहस्तमेवमेवेत्यर्थः चतुरद्दहति उ
पेक्षमभाष्यत्तत्वैवत्नाप्पादित्तिभावः एतेनतेऽद्यवद्दृहंस्त्तेवोह्यतत्वच्छेदहृतेरोपह्तोकास्पापत्तं पूर्वपर
मिति येमानदस्यादितिदोषः लिंगविशिष्टपरिभाषयेति नव्हाद्यस्यप्रथमानिर्दिष्टसतेना लिंगविशिष्टप राम

रिभाषया ज्ञापतीशाद्रस्यापि ग्रहणेनेपमजेसत्वेस्तितिज्ञाहसारः पूर्वनिपातन्तरस्निशेषपूर्णीनान्वयः विशेषांतानि
जि पराः तो श्लोमोपस्येतिविप्रस्वहरवीहावविजमानवरूपाभिसर्थः महेतानुमेहरूतिशेषपागानास्वपदेवहुवीहे
नीत्वपरस्त्वरा: सिप्थतीसुच्यतेतत्राचेत्समवषाशेनोहहतामिति भावः अबकोरोतीति समासां समासेकेति डान
पतीत्यर्थः द्वित्वत्तमेवमिति सवर्णेदीर्घो पूर्वमेरा के निगतोत्वाहेष्वेवेष्यः आगतिकानिसीलि भाष्यानुक्तत्व
दितिभावः पत्वत्वामोवादितिभावः वितापाचेति चेनतुकोपिमत्यपेमत्वेनममत्वाप्रियादिसमाहः ततरीचेति
तस्यत्तीत्यामित्यर्थदर निमिति लिंगविशिष्टपरिभाषपेति भावः परिज्ञाणेसामथ्यहृद्वगातेश्वेतिनिपेपापरव
जिरितिषोध्ये केपरति अनेनहिकिंपदेनक्षेस्कधर्मिताकेनप्रत्यस्यसनिरासेन महत्वपर्वक्रास्हिरूपस्प्रगृणास्यग्रहणं
स्त्रविते अत्राकविसोऽंतु मेझातिकहरनतदिनानलेमेत्तसर्वनापमध्याशवृतिरितिः शब्दोप्यगानुकर्व शादृहत्याकडा
रत्ववस्यभाष्यविरोधः अपचमसर्वनामेतिस्पष्टमेव प्रगृह्यास्त्वेति श्वेपरादतिम रेतभमपसेलात्वित्याभाष्यमपोगे
पिमात्रे तस्यमपत्तान्वेनाप्यागृणावचनस्त्वेवाश्यं कृतार्थेतीति कृतार्थे दुःस्वशीलशब्देप्रिपादादितिभावः समासे च स

लघु०

पिको ऽयं ख्यातइति इत्यवती संज्ञा पिनेश किमुत दीर्घोर्थ इति भाव्यस्यात् भिन्नोव्यात्त्वेन संज्ञाशास्त्वात् भाष्य
रीत्या तद्विशांतत्वेनाभाग्गशाव चनत्वाच्च त्वेचेति इद्य सत्सूत्रस्यैवेतित्वोध्य ऐसहितेयरति पुंवद्भावे सिद्धस्य मत्स्यपविस्य
नाश्रिसेदं नराभ्र्यपेत रोहिणितिरित्यापजिवी आ संज्ञायामिति पर इति तद्धतीत्यर्थः पर्यसंतेति लिंगविशिष्टपरिभाषाप्र
सर्षः इत्यविरोध इति एवंच माधवानुसारेणापंनिमित्तइति रूपवित्तं स्वार्थंचेति तत्र नरपे मिद्धनिपातनन वि
वाहनिवंधनपतिशब्दघटितस्य सविग्रहितस्य सैवकिरांहितस्तौमावयोधकत्वेमान्यासां येचानिप्रसंगाभावे
न सूरिकेत्वेमानोभावात् तस्य ऽभाषितपुंस्कत्वेन पुंवत्वा प्राप्यापुंवत्त्वे वा धुमार्थमिति ग्रामस्याशेष्येकिन
वृत्तीयस्य ग्राहेयोगार्थश्च इति निमित्तकुमवद्ध तेलोकन्यायाहारपासमर्थायावारतोनवस्थौ विशेषस्यान्यप
तीरावृत्तोध्येत इति भावः अत एवसमानस्वामिकुशस्योर्नत्तथाव्यवहारः कुंवित्तथा व्यवहारत्त्वो गौणः किं
चविवाहनिवंधनः पतिशब्दोनीत्वेप्य स्वामित्वेनैवसवोधकः स्वामित्वंच प्रकारान्तरेणापि नत्वायत्तात्फलेनेहा प
तंकरोतितस्य व्यतेक्याप्नोतेयपातिशब्दः स्त्रियांपत्नीतिरूपं तत्पत्नपनस्वरूपसाधकत्वेद्रूपणानेरमाह
किंचेति सायत्स्वितिप्रपद्येति अत्र इत्सूचयतैतत्सापत्नेपुंस्त्वे प्राप्नोति एवं च तिसापत्नइति भाष्ये नेतीतिभां सम

प्यके पर्यवसितं तृतीयस्यभाषितपुंवत्त्वाप्रतिः सहिमम्यानस्वामिकत्वेन गृह्यमाणमाह पुंवत्त्वबाधे हितरसंग
तिः स्यैवेच किंच विवाहनिवंधनसत्वे तस्याभाषितपुंस्कत्वेन तथाश्वयसापत्न सिद्धेकारसंगतिः नच सापे
त्ने ऐवने सिध्यति सापत्नो पिसापत्नी तिभाष्यापपरतिवाच्यं द्वितोयस्तत्वेन तस्य च शिवारौय्यहुतो
नत्वतोपादेयो ऽभावेस्यमो धवृ तीस्या सपत्नाप्राप्तेरिति इति केवलयोगिकस्य ग्रहणान्नेति केवलयोगमा
त्रेण वृत्तिनिमित्तकत्वेन सर्वः तेनैवस्वविवाहितत्मेति विवाहितां लिप्सतेन नतत्त्वेन व्युत्पत्तिविशेषस्य
वाधनाचेत् स्वार्थं निपातन सत्त्वे अत एव स्यभाषितपुंस्कत्वमिति भावः यद्या केवलयोगिकृपातिशब्द पारि
तत्स्य सत्यर्थः एवंहितचेमिरहातभाष्यं सापत्नः प्रकृत्यंतरात्वात्सपत्नशब्दः प्रकृत्यंतरमित्यस्यार्थः अ
न्यप्रकृतिपुंस्यात् प्रकृत्यंतरात्वात् सिद्धार्थः प्रकृत्यंतरमाह सपत्नशब्द इति अत्रत्तत्त्वनिरूपितप्रकृत्यंतर
त्वेसपत्नशब्दस्य स्यादप्राप्नोति पत्नेनह्यतोऽन्यः इत्यभिव्यक्तश्च गापातच्यायामास्थानवनमाने एवंचसपत्नीतिगण
पाठमात्रिस्यसपत्नेकृतिकसपत्नी सपत्नीशब्दस्य नकापत्नसिद्धा वपिसापत्नोपिसापत्नी तिभाष्यपदे
पक्षः खसंमत्ता प्रकृतिर्गणे नसपक्ष्यतेकिंतु भिन्नः सपत्नशब्दः तदा विलिंगविशिष्टपरिभाषयापि नानेरे

१९

न्यु.२०

राक्तिध्यति कास्वलाषान्यचित्तपूशिक्षा हिपोह्दा कोपिवाख्युकाज्लराणयः सर्वंचकेनस्त्येयोगाकृपति पावृधारितम
प्रहांगोनेतिमच्चमेव श्रकुंमसेहिह्दामपसपत्नीशब्दश्चशारनचमाप्रवक्सस्तेन चनपलाप त्नपाद्भ्रमाद्र्त्सादिनामा
वग्रयेनचनस्यतंतेहितीपसपत्नीशरमारुपवित्रोधाभावश्चोपपादितः सापत्न्यापितिपेषामस्त्रसपत्नेप्ररुक्ति
कात्वज्ञात्याहित्वात्त्वविरोधः सूपन्नसक्तातिकोपितत्तैमपसपत्नीशब्दोपेष्व तत्त्वचनोवेत्तत्त्वपोगात् रु
द्रशोरेवग्रहणाद्विस्यमसल्लेदारस्पा अंगवित्रा शिष्पविभाषापोजल्यकलितिकेऽनेतमन्त्रचेतार्थः तपोम्ब्रद्धस्त्वा
र तत्तीयत्त्वपोयक्तः सन्पयाः सापिसपत्न्यस्ते मत्त्यह्रणाचीत्रभावः मध्यमाचयोरिति व्याख्यातस्तोत्र
ध्यमस्यचन स्फृत्वधयिजसम्प्रह्पोगिकोग्रहणाः स्पाह्कवत्सोगः त्र्यतेमव स्तेत्रेणसिद्धत्वादेव प्रकारोणा
स्पचेति अनंतरेस्यतिन्यापरितिभावः असमाविसत्वाश्रिति इस्त्रिणात्तराभ्यामतस्त्वह्दि नामानोसनपाः
स्त्वपोभाव्यपाश्रादितिभावः तद्धितस्पवृत्त्युपपत्तिसमासः अव्ययमेवेति पतन्त्रदेवसोरितिनियमार्थं
तद्धितेवेत्सर्वनाम्नः डवृत्त्वनहिकच्छमोरवेतितलोमपडेघंतेः निश्चमेकमुवत्तुमितितनचरेडिशोनराभ्या
मतमतितनियमार्थं तद्धिते भवन्मपरशि समसकतवचनेर्वितिमयर् ड्राससीपर्वद्दीति सर्वनाम्नोसमासन राम

सेनपत्वसप्रालसत्माहेः पुंवत्त्वापत्तिरितिभावः उक्तोरहरणयोरिति संज्ञोपसर्जनयदितोदाहरणयोरितुर्थः
तेत्वसर्वनामसंत्तकत्वमेवाभावोवेक्तनस्त्वणाच्छत्तिभावः अतिसर्वोशादसोति उपसर्जनत्वासिद्दसत्तापुश्चापि
करणोति द्वेतोहतेः प्राकत्वार्थः वैयाकरणाभोपरति नव्याभ्यामितिस्न्वाद्येकोपहरस्मान्तरोधेनरं भाव्यरति
यकोपधापारतिसत्त्र्येहतेषर्पः इस्तुकेरिति इतिनशब्दस्यादेतत्त्वाभावेनततोजातिर्नसंशोडीषः मामेरिति
मोषः अनन्तः इस्प्यपयमुदाप्तत्तेस्थविन्दृहस्किंतिनिषेधविधयोन्तरमन्त्रविपपेकर्मधारयेउदाहरणात्तुव
हुव्रीहावीहरशोपुवत्त्वनिषेधवत्सरवेतित्नवाच्यं उक्तशास्त्रापेतरनुवर्ततिंतन्नायीदृशार्थकत्वमिति ध्वनायित्तत
योक्तः इत्विजेरस्नतापत्त्वत्वेमाप्यमतेजातित्वाभावोत्त पारस्परोति त्र्यपेरागिस्पेचहितेनापिडीनेकोकरोतिभावः
यदित्वन्डीषितिपात्तेदान्यकरवित्रोधोवाध्यः व्याख्यानमेवात्रेति मत्राहरोस्पुठेतित्ते त्नपेकमत्त्वकानित्यत्वम
वकमित्सन्य सामानाधिकरण्यमिति इत्यनामममीपिनरत्यर्थमाह उपकात्इत्यादि उक्ताराणर्थेतितत्वापंकमत्नेका
त्मीभावेनतपरत्वत्वाप्रश्लेतारितिभावः मसात्योतमिति अव्युत्वतेकेनातसोस्परेहसागतस्याविशिष्टत्योपादान
विषपत्त्वमद्भूत्वपिवाध्यं विद्यमानतावाचीति इत्यानेपुत्राणामविद्यमानतेरसमर्थमत्स्त्वितमाह इत्यादिति

लघुश० अन्यभिवंगादिति पूर्वाह्नस्समाहारपंसहपूर्वाह्नमिसारावपिनत्रयपसमप्रथमा निर्दिष्टत्वेनोपसर्जनत्वमस्येवेति
भावः अन्नुयेवहारकमिति समासस्यापसर्जनेत्वीसंभवादिति भावः यद्यपि सहकेत्वमियस्यादेसमासस्योपस
र्जनत्वंसंभवत्तथापि लक्ष्यानुसारादेवंव्याख्यानं बोध्यं उपसर्जनं सर्वा पूपवाकस्येति केचिन्दूपयवः सर्वात्रो
पसर्जनमेवेति विशेषणात्मानमर्थादेतत्तन्नरतिभावः तोहशश्च बहुव्रीहिरेवेत्याह बहुव्रीहिरिति व्याख्यानान्त्रो
त्रोपसर्जनत्वपूर्वे नत्वौकिकेशास्त्रीयंचततारव्हतेति नसपत्नत्रसपारावपित्रपसर्जनसर्वावयवेकत्वबोध्यं सपत्नि
इति एतच्च कृत्यनुरोधेन अत्रत्र सहविद्यमानः पर्वोपुष्पा इति अनेकमन्यपदार्थेइतिबहुव्रीहिरित्यन्ये अत्रसत्रा
चिवेति अव्ययमारेरित्युक्तत्वोरित्यपिबोध्यं अतत्पगाविशतिरिसाहेम नक्षत्रेपर्हति तहेतिलंचनेत्थशस्स
तत्तामानाधिकरणपात्तेन नचुइतेतापस्पूत्तवचनेतामूसर्तिसिद्धसमासे विशेषणात्बहुव्रीहेर्नस्यैनेतित्वा
होवः साहेव उपलक्षणमिति स्पष्टचेरगातिस्त्रैतिहत्त्रेभाष्य अव्ययीभावारिप्रांतयत्पत्रावा मि:मंन:कयसत्रा
तिव्याप्तिरितिभावः सामानाधिकरण्यपासंभवादिति यद्यपितःकन्यासिसारविव[illegible]नीति मध्यमस्यन
पूर्वपरत्वे पत्पूर्वपरंततपरत्वंपनधमेकाद्रस्येतिभावः पूर्वपरश्चेपेइति योगिकपूर्वपराश्चेयेइत्यर्थः अकारांतेचेति राम०

कैपत्नपरस्यलोकेनलड्मर्ये केवला अधिसादेसजातीयान्यभावेसदृप्रयोगोगत्वहुव्रीहेर्मानाभावादिभावः
एतच्चज्ञादेरितिसत्रेभाष्यस्य निवृत्तिधर्मेति प्रवृत्तिधर्मत्वसमापत्ने इत्यादि रमेति जंभेहेतेः सतेस्मनिषत्तंसोम
पिवेतितदर्थः मधुजतहति रूपकेतोतिशेषः इशिशशिविनोकिकविवक्षात्समारकेत्वात्तस्येतिभावः कुमंव्यति
हाः पास्पारपहणादि अव्ययीभावत्वादिति तेनेतत्स्पोव्ययत्वंबोध्यं एतच्चहसोदित्रुमाआपादत्यर्धितं एवं चतता
र्थमपीति इरेसातिविपरस्त्नीपत्वोनावपुणेन परितइएजीव्यत्वेनवहुव्रीहिसत्तापोस्माविशेषिसनिशिष
स्तरवन्नीपत्वेनाव्ययीभावत्वपद्धमसमासोत्तारातत्वेनसिद्धिरिसव्यतेतहायमेवप्रयोजनमितिबोध्यं समा
वेशफलंलिच्चप्रत्ययाव्ययत्वपो: सिद्धिः तन्नेतनेरमिति अव्ययीभावप्रकरणेइअपितत्समेसंतप्रकरणेएव
तनेकतःहृदिइष्यादिस्पष्टत्वात्त्वच्यरस्याकर्तव्यतापतिः चनेषाधनुपाचेत्प्रवर्तेतयदेमित्यत्रैनोपत्तेः सिद्धांतेऽ
स्तात्हयनेवेष्यते विषयविवेकोक्ति यहादिरूपान्यपदार्थपित्यर्थः अपपाहस्पामंरेति इष्टवेदमाष्यउभाष्योह
त्ताम्यासमत्वविभाष्याते तथापिसमसुपनिपातनेरेववहुव्रीहिर्विकल्पितत्वरूपादयमव्ययत्वाभावामोन्तके
हरमेप्यव्ययत्वफलंबोध्यं आत्रिस्येति आरोप्यसयर्थः रवतन्त्रापीति जान्नुवाचीत्यर्थः उपन्नइति जान्नुसमीपमित्यर्थः

एकदेशस्यैवसम्यविवरणमविभागेनेति अवयवविनोद्धिविभागेन समुदायात्म्यमेवसंबंधस्य चेमकृतेपीतिर
वेत्युक्तेरथ्वनन्वाह एवंचगुणोति गुणोपसर्जनद्रव्यवाचिनस्त्यर्थः एतवेत्तद्वतिविषयमेवायांवस्यत्तोरशत्व
मिप्रतिनपरासपरो।।तिमत्वस्थेत्सियप्रविरोधः एतदेवाभिप्रेत्यभाष्येकेपरपेत्तत्कुकुमाघनुलेपनमपिरेवक
गोरवस्तोरविभागापन्नानिलीनेपरिविवक्षितेत्तहोगलणां धिर्हेवदुत्तरति विभागेनावस्थानेतुमणावश्यते।ति
भेतद्व्येति चंदनतोत्वाविशिष्टद्रव्येत्यर्थः संगाद्धिवाद्युलित्यत्रापिांधात्र्यमाणानांतत्त्वमस्यानांवाद्द्व विभा
गापन्नानामेवग्रहणमितिनदोषः एवंमत्वांधिप्रयुप्यसालिंलेवत्यत्रापिद्रव्ये कोशपि द्रव्यवश्यमेरत्वप्रोक्त
एवोर्थः।न्याग्रापी।।तावितन्वहनवाक्यप्रोत्तहत्वर्थः दुर्धरेति अत्रचेकेचिदित्यत्राचोहु विचीर्जतुतोदृष्टार्थं
त्वेउक्तभाष्यादिविरोधश्चेति।दिक्।।यदेवत्यादिनोक्तेचितं परनिपातोतायेत्तोपकात्र्यपरताद्यावश्यपकत्वोत तथ्य
मपत्नोह दातिविष्वदति इहेवबरस्वरतिचकथंतहीति तेषात्राभावेन।।तिपांसंज्ञापामित्यस्याप्यप्रामेरी
तिभावः नघत्वेवेति।सिद्धेरति।इहलक्ष्मीश्चन्द्रमात्रविषयपमक्तांगतांलक्षन्येषुश्रविभक्तिकपाठेकार्येमवि
भक्तिकपाठातद्विवक्षेतिवाध्या।एकवचनस्येवेति। तस्यपदत्कपेवेत्यर्थः।सिद्धमिति बहुवचनातेनति

प्रत्ययातदाह। अत्रलक्षा हेति।।बहुलक्ष्मीकइति।।बहुीलक्ष्मीर्यस्येतिविग्रहः सत्यामादिकमिति विशेषविधित्व
त्वेनास्येवोचितत्वमितिभावः निषेधसूत्रेणेति नतस्तेहीत्ता।निह्वेनावृत्तावतस्यपत्वेननेनतस्यभाष्यासंगत्वा
रीतसूचितं स्यादिग्रपामितिं अस्निनायाप्य उभयपत्तोनोचनयत्रनेनात्वपः तत्रपत्तेनेत्रुत्रस्थनारके
मेमेमांतेयपंतेनोवृद्धिदिसिमवताद्ध्येनतस्यपाद्धपेत्मारेस्त्रवस्यनशेषा।।विकारेषुदित्यस्यत्ताभरति
धे वाचापतिरिति इहवसमासांतमा चरपेसेतोपत्वमितिसिद्धरकेपरापानुरोधेन अतति ववहुत्रोघेधिकारेप
स्त्रयपत्वेनकवेपत्तेनापिसमासांतेपसामितिबदेताभाष्यकारस्यमतेलु नेरुपता किनुत्रतिपरोकानम्
श्रुणानस्पादेकेत्वेकित्वनवकाशेन नवाद्धतालिकवभावेसावकाशत्वादितिरूपातोऽर्थ्य तरेरमिति वि
शेषाणाशेनपरिच्छेदकेगदहरस्तनिमित्तः एवंहिपहः।।स्पविशेषाःसंतीतिनिर्जातेतस्यरिहेरायवगमवृ
तिमपकृतत्वेसा।विचारत्यस्यापत्तिः तस्माद्विशेषणात्वेनसिद्धवपिमहनीयरतांव्यभिकरणसमासोप
नार्थमिस्यवतात्र तत्रकोदृष्टिस्त्रमप्येवेति इरंविषम अनुवादत्वात् तस्मादिन्नपदापोपहस्येपारप्यमयुक्त
प्रथमानिर्दिष्टत्वसचानियमेपासेत्तेनपहार्यविशेषणेस्यपरत्वेनिपातार्थेमित्तमितिपोध्ये चावैति

लघुवृः

त्वात्मित्तेपरस्य निवृत्त्वीहि:॥ ॥इति बहुव्रीहि:॥ ॥कर्मधारय इति अन्यपदार्थे तत्समासाधार्यं परस्य विशेषणत्वं
संभवतीति पद्यवृत्तादि वहित्वविवहि: समुच्चयमानमपेक्ष्यतामिति एकार्थाभावे विग्रहपाक्तितिशेष: नेवेकस्येत
मितितस्यैवान्वयादिति भाव: द्वंद्वमिति पूर्वपदार्थ इति समासविग्रहस्य विशेषस्यवान्वयतावुपचर्मेर:
मस्येति एहितावुपचर्म इति अन्यपदार्थमावाम्य बहुव्रीहिविधेयार्थमावान्यद्वंद्वस्याधृततावेतितत्त्व वशंरा
तेभावविशेति प्रहृति विभक्तियो: सामानाधिकरण्यतेन्नावार्थ:नीमूलसमानाधिकरणोत्पन्न तत्पुरुषस्य नित्यत्वात्
तिवोध्याहार्य इतिभवितोक्तार्थाभावोपि लिभाव: द्वंद्वद्व्यपतिरिति नन्वयुतादृश्यबित्वेनतत्त्वपदत्वात्
यो: सहविवक्षा: संभवेनकथंतत्र व्यपति: सत्यवेदं विशेषणाविशेष्यभावस्य तत्रभाष्यकृतपरत्वेन नव नमगुणाभ्यो:क्रि
यो:कियपाश्चतत्संभवात् अशोमानभावेनपरविशेषणस्य विभाग्युपयोगाव विशेषणामितिसत्त्वेति नेत्वत्तरा
कार्याभावात्तिरितित्र सहविवक्षाभावादितामत्पयत एवेनोत्तात्पनपारमेदशत्तापि भवतित्व्रमेदादिपदान्वयत
यो:समानाधिकरणपर्स्यपश्चात्मेनमाप्तृतीतावविद्ध्वंसनपदसाकल्येनाप्रोक्तत्वविवक्षायामितिरिड सोमाय
वेति मार्ष्टेवेरापरापर्वविशेषालछात्रिनि॥स्पर्श: समाहृतोद्वेति समाहारद्वंद्व:प्राप्यमाहिनमेवेतिस्पर्श:॥ २५

अध्वर्युशरदिति अध्वर्युप्रणेता: संबंधाभासितमाहितिभाव: वयत्तादिति व्यक्तिमावान्यविवक्षयाननिर्धा
सकृत्तनसोनजनस्य विवक्षितत्ता इतिभाव: वेत्तारीतिनरोदेशशतिभिन्नेपरेद्वंद्वेद्विवचननपुंसकेचस्यात्मा
पर्वमितिभाव: जनेरादीति जनानांपदस्थ नंपदेतिस्वस्यामनुपदस्थमपावपदस्त्रेच्छे: ताह शेतत्रामनगार
घपिजन्मपद्दशायातदिशेषपदस्यसमाहार अतएवेति यत्रभाष्यमुदाहीन एकशेषावाध्यतइति निपातनेने
तिशेष: गोत्वश्चादिति एवंपदर्तं तत्पदस्येपिनेतिवोध्यं प्रतिपदविधानार्थमिति सनपुंसकमित्यस्यप्रतिपद
विधानत्वाभावादित्यर्थ: तदेवापपादयति तद्धेत्वनहेति एवेक्षान्वभाजडेति विनिगमनाविरहात्पावकृतभाष्य
इत्यर्थ: प्रतिपदेत्वाहिति अनयकाकवेस्यपिकोध्यंविधेयेपापितत्वनन्दगेषुकनिनेहतावस्यानिपूपार्थत्व प्र
लक्षणहतामिति विप्रतिषिद्धमित्यस्यार्थ: तत्सभावहारस्यवाविनासमाहारद्वंद्वएवेत्यर्थमलतेशतरेतराद्वंद्व
नापतिरितितद्दशय: इत्याह विवेतिकामक्रोधपाविरोधाभावपिसमद्वंद्व:द्वारेरिवेश्यभेविनाभावेनानि
युक्तपावर्त्यकोदाप्रवेदात चेनविभावानुकर्णागनेपमर्धावाचित:तदभावेसर्वनियम:वेकल्पिकोप: समा
हारेद्वंद्व:मोदुञ्चवाविनामेवेतितिपमोदेच्वेतरेतरयोगस्वेतितद्दशय:विरोधप्राप्तेरिति विप्रतिनियमे:

शुकशङ्करः

त्रपासिकेकवह्नवमेरत्वेत्पविप्रतिषिद्धानामेवेतिनि ज्ञातिरप्पाणिनामित्यपिनचार्थेद्वंद्वस्मेतद्धितिलमाहार
द्वंसोनिपममोत्रम्यवबाधप्रमामान्यवित्तपाःनेननिषधात ज्ञातस्यवेसवजापसाःप्त्वृतितगर्थेःपरिमाणानिपम
इतिसिद्धेःत्रपासिकेकवह्नवमेएतेनेतद्दोवःस्पष्टःसचेमेतस्यकेतस्येवव्यास्यात्मा इतिभावःनियमस्येति
स्ववपवृद्धशब्दस्यान्यपरस्मिन्समासःग्रहणाति नेवंवृक्षमाहात्म्यशातानम्पविवृक्षापापमतसमाहारानि
पेधोमत्वृतिवोच्यःइत्यसमस्यानेवगामनेनतत्ल्वापमतेःमधानस्येति मपतस्प्रोगापमात्रिवृद्धस्येतिनिपम
दितेशतरपाणामप्रामोतहिधानेनास्यवृधातापंम्म नचनिपेमनिषधेकमपाणपतिःत्र्यमात्रत्वेनसमाहारोतरमा
भूतितिभावःइतिजि शिष्टत्वकृतोतरपाणोप्यहलाभेपवःसमहेविशेष्यइतिभाष्यमतेमायेभ्रेत्सात्तस्याप्यप्र
चातेःकिंत्वेपरस्यएहारकमवधेनसमाहारेपतरश्चलान्यपविवृक्षातेरास्यवसमाहारेद्वन्द्वपोमिःमधानस्य
वमापेक्षत्वाद्यसमस्याबृंगमावकिंवाचेममप्रागमासावनिपमामास्यश्चोकेस्पेनेननिषधःस्यातत्समात्स राम॰
वेमत्वद्धपमप्पमपेतिषधःअत्रसवेत्तास्वत्रविषयेसमाहारद्वंद्वसिद्धिःसामर्थ्येनाममर्थ्यासमासकल्पना
पेक्षैवेत्पमन्यषकल्पेनसंवेविस्पारिति अव्ययीभावस्येवेति समासान्तेगवचनत्वाशिरितिभावःपादित्विति एव

वह्नचपक्षेइतिशेषःनचबहुव्रीहावन्यपेक्षोत्तरपद्रतामिस्वसेकविद्विःउपरथास्यसेवेचितत्वाद्दितिवाच्य रि
गाणोकपीत्वाद्वहाराकसंबंधेनसमग्रसाप्योःनेपनद्वहौपःभेदेनान्वपाद्दर्थस्येवह्नवेनततिहेरात्इउपरप्र
स्येति अव्ययीभावान्वयोगात्अप्रपततघानरेषरतिभावःअव्ययीभावानुप्रयोगात्समासान्तविकरणपेत्स
मीपिनेत्रमेदविवक्षपाप्य स्तरेतरयोगेनवकुव्रीहेर्वान्प्रयोगात्तिप्रसमीमिवानित्वात्तसमानोलिंगव
चनत्वेतस्पृतत्वनाव्यपीभावान्प्रयोगःअत्रानसहवाचेतेति तत्वंचैकहविर्भागित्वेनदेवकल्पसद्भवप्रसिद्ध
तपोलोकेपमित्हमाहचर्पत्तयावेत्यन्यत मास्युकौ इति तराधंमित्यन्ये अत्रकोसमर्थेति सचेत्तस्कैर्तिवोध्यं
निपातनेरतिशब्दोदेवेरकोसीमलेवामिद्र पितमानस्वरक्षंस्मिमानस्पितरावितिसूत्रेद्वपविषपरपुंसेतरप
रस्पाराबितिभाष्यतृपतितेषरणाःसतःपूर्वपरस्यस्यपोपरेलपाकपैरेनव्याख्यातमितिनतद्धितोथाः
अत्रएकेतपरदेरस्माभिःकुक्कुटलप्पनवाघरतिरिक्कवाकुस्वजलचरमिति सपर्धमत्रधाप्यप्रयोगाद्देवगवर्दस्त
स्वेपिवाकृशादसपूर्वेनिपातः॥ ॥इतिद्वंद्वः॥ ॥अपसमन्तहैतमितिपोतप्रभस्येपसमित्यसर्षःपने
ति अपसाविशेषसर्वेकेनपुंवत्शक्नेनसर्धःतस्माहचर्यगणप्रसरोपवासकस्येवहदर्शस्यग्रहणानाऽह॥

१५०॥ पस्येत्यादिनासंकेतस्येतिभावः स्वनुल्लेखेति साक्ष्येसतितन्त्वसाविशेषस्यैतन्मयत्तिरितिभावः निपमते
नत्वेत्यादि मूलस्थपाणिमित्येकरोपेतत्त्वोवृत्तुकस्मात्विशेषापत्तिः नचेदोपत्तिःकेमयरसविरोधात्तेत्वहिंसुमान
।विषुल्लकशेषाज्ञायोत्वेऽफं नचतस्यहित्तःक्रोषेपुन्वयुंमकतत्वकेरेत्तविसंस्पानियमेनत्सिद्धिगांत्वाविसचात्
हेयनविशेषइतिवाच्यं अहंहत्ततुरूपविशेषणानामित्यत्रइयहेनतुसपवाइकुशेषस्वस्यपुल्नस्यगौनतद्मा
प्रीतिभावः अहिनरेति ताभ्यत्वोलक्ष्त्वाभ्यांतरः पुपोनाहिमात्वेन्तेदोषादिविहिस्यर्थः तात्पर्यादि चेद्
वेशेषपरोहेनसामर्थ्यंनविशेपस्त्वेतत्त्वसाएवसम्बन्धेनेतिभावः तन्त्वसाणसंचलस्यव्यापर्थमाह तेंद्रे
द्रोणेषाविति मातेरमपीति पितलाणेपुरालस्थेः सराहिमिवेति सर्वपदस्यधात्माणमित्पर्थल्वध्योयमच
कारः इत्य वार्थीमाभ हितिवान्त्वयः संवीरिस्मल्लस्यशोहिमिरत्नेष्वत्वर्थः शरपरोनिपातापर्वोपस्पादिः
आघादित्वादिति पेतनुसकेतहसत्राप्यचमेव किंतुविशेष्यमिति अनेनेतांगत्वार्थलिंगबाधनेनचरितार्थ
स्यावहिराद्विशेष्यसंबंधमात्रनेगवाधकत्वेमानाभावादितनापमहत्वमस्यसविनेत्वतस्वैकशेषविशे
गपिसत्यादितरस्पसाम्रवृत्तिः अतएवउभौसंपेत्रलोकापुगावहमाचारेति।तिभाष्यप्रयोगः संगच्छते तस्माद् राम०

सत्ववृत्तेनैवैकशेषः अंतरंगत्वादिति विभक्तनपेक्षत्वेनततदुत्पत्तेः पूर्वमेवतत्प्रवृत्त्यर्थः कथंकमात्रपरतेपीति
मिदीत्यादेरकार्दसत्वेपमिप्रतावेवपवचषीसेनालोंत्सभेत्पस्यमहत्ति वेध कल्पमात्रेणाकहसस्येत्नोत्सापवा
त्वव्युवहारइतिभावः॥ ॥इतिएकशेषः॥ ॥कोरोणत्म्य इति पतघरके: पदेपरत्वान्नित्वादार्थसेवातत्तम राभि
धानेमसुरायाभिधाभिःपयस्यसमावृत्तिः विशिष्टार्थविषयकमिति एतत्कूत्सपरेणतेसंबंधवालिपृतेपशक्त
मित्यपरात्त्रिप्रहाकोरसात्तत्वेत्तत्वहिपपकल्पमितिभावः पपंवस्मानगत्पात्तस्मादन्यवप्रकृतेत्वप्येपमानमि
सन्पत्र राभ्यतनमेवेति तेत्वोकतत्वामत्सस्वयः तस्वत्वविशिष्टकापाध्यानिलसत्मसाह अनुसवेति मीमां
सकावामित्यधराधिकरणावाधिकिमस्पष्टमतविभताततन्मरेदेहमः पोगात्मतीव पंकजादिपदेइतिशेषः
कुमेशत्वयत्तसाधितपेति कुमपाकिकल्पप्रवृत्तिप्रवृत्तिमवधत्तपपात्तसर्थः निरूपितेमपोजनाभावादितिभा
वः एवंचव्हह्रीहाचरमपदस्पवेतत्त्वाप्रिधमत्पपादेलंस्वागपेवोपपत्येममरायशोकेद्रेदकिंसायंअपेति
हंताविति अन्ययपतिमतिसंधानेविनापितेध्योतसपिर्वोध्यपादस्पेदेति तेनवहमीहेपेरेपानिसत्वं कु
म्भसेविधौ किंचवातिमितिकेवमिकपीतिसत्रेच समासमिति अनेमकारागात्पत्रसमासःमस्यपर्तेति

लघु०

षोडिमैवप्राय्विभाग्स्येष्टसिध्यर्थत्वादित्याशय पद्यपिसर्वत्र रमेवेतिप्रवेषु केनचापि लभ्यानुस्मारार्ह
त्विन्यत्रापिमहोनवाचकमितितात्पर्यं॥ ॥इतिमर्वनामसंज्ञाः॥ ॥तहाचकेति व्यस्तसमस्तपिधवीचकस
र्यः भाष्येलिनि अनेनविशेष्यस्यान्यलिंगत्वे सापेक्षत्वमसाद्धितिमचितं गातिस्यैतिरूवृत्तेति तुपलगोरैतति
मत्त्वनाष्येपिरलोप्रयोगो वद्धिवीति क्रिप्रयोगोऽपमगलेऽपमार्गा इतिकालेऽप्यहतः मतामलस्यप्रेषपत्ति
त्वाहो क्तिपोदिस्येस्सर्थः पयाकारेति नलुचपयोश्रयत्वे नपपयाकस्य चिदाश्चं पठेति पठेनाभोपमेति
विग्रहहतिवाश्च येति सोममिति इत्साहिश्शरेस्सानवु नकेत्वमेवेतिमतेरम पुंस्त्रिपत्वेतलपष्पकाचिम
मेवविशेषएवेन द्वितीयोक्तमाक्लोके वंविनापिसंबोध्येषु संतेनसर्वतोव्याप्ते यस्मैमान्त्रईति एवं
चवलमह्यहीप्यसुनिवसीपईतिमुसोत्वमेनस्य इचेत्रेतिरीयापनिष्टः शोकामाप्तेतदाति केव
वलमेतत्शोदाहीपत्वेनिस्तस्माईवनिपातेनोत्साध्यितिपश्चांतरमपितत्र विषयमिति विषपमतमित
र्थः स्वाणेनिषयंतापाईति तेनाशीर्निंदु तममभिव्याहारस्यवास्य साधुत्वमितिभावः प्रागवहुर्वीहेति
वहुव्रीहौसंख्येपरत्वतः प्राक्तमांतविधेभावाद्बहुव्रीहौमकथ्यतोगीतस्येवतत्वमहणमितिभावः राम

इतिसमासांताः॥ ॥लोकान्तुकिरिति लोकृशब्देहेदिः पयोक्तनंतषेधाश्वशब्दीपाइति व्यापेमतविति
निमित्तत्तुकोविनिश्चितिरितिवेग्यं समासशास्त्रेपठिताशब्देतिष्ठताश्रयपदासिद्धसमासस्यप्रतिपदोक्तत्वोस्त्वा
केपतिकेत्वस्यैवग्रहणेनलुक्रशोवृत्तेकेविमझेपठितानामितिभावः भाष्यवार्तिकविरोधइत्यस्यैवव्या
ख्यानपरंग्रन्थविरोधइत्यस्यार्थः तमत्पयायपयति विशेषमालाहि परंतुतेषामंगेपयाहस्यपदेतिमन्त्रेणादिवि
पादेपहेतमित्याद्योपहसादेवकारणपाविशेष्यविशेषणभावव्यवैपरीत्यसम्यन्तत्र चमत्रेभाष्यएवाश्रयोनात्रा
पितव्याश्चपृणावाधकाभावादस्साहुः श्वाम्पतीति श्वात्तापिनिच श्वात्मनश्चपूर्णोऽपसंख्यानंकर्तव्यमि
तिभाष्यश्चमत्वं श्वेमेनलभ्यतेति नचमोपहारस्यवित्यत्रोपमत्वाभस्य कोम्येरित्यस्याणः स्वरत्वचान्तव
तेरिवात्रापिवीतिके हश्शनुचतिसंभवः पक्षपास्येव तेषापाकरणस्यापामित्यनेनैकमत्वेवेनपाराव
प्रतिश्रुद्धितपाव्यास्येनतचालमाशदस्यपहणामितिवाच्यं क्तिश्लाइकमत्वेनत्वस्थलादिविहद्धान्न विवे
किनामिति श्वात्मनश्वेतिमचेन्महणपतिवेसनुहत्तिप्रवेशमार्थमाष्यसत्त्वदपयहणं श्वेतमकात्मनश्वेति

लघु१ च:सार्थक:वार्तिकव्याख्यानमप्येवमनवद्यं स्वाद्वेत समुदायत्तिकल्पात्तापि निवृत्तेन त्वाभ्युपगमात्वन्तान व्याहतमेवमिति
भाव:भेदपरिकल्प्येति अमलत्वेन वर्तिपदार्थमात्राभाईनत्वेनान्यपदार्थत्वेनेति भाव: अधिकरणत्वेन विवक्षेति आधृ
गतत्वेन्नाहाविवक्षया तत्समानाधिकरणव्याप्यादनेनाधायत्तत्वविवक्षायां तत्समानविवक्षेत्यर्थ: अनयाप्यरत्नाके
मनंजपेनसाव्याधः स्यात्स्वाधिकरणसंज्ञाकमनसंख्या धातोरिह प्रविशतीतिपद्धत्वाकेरणस्तेभापदत्वदनुत:फ
लाभहृदपविष्टनपास्तित्वाविनामनपद्योगमसाधुत्वमित्याह भोभ्येवेति इत्यत्रास्येवेतिरन्वयो तर्थ: तत्पुरुषे कर्मे
स्यापिनोभयत: नोक्तदोषेति अनित्यत्वान्नलुप: सिद्धिमत्राभ्युपगान्तुक: प्रामिरितिभाव: तदुपन्यस्यति इत्य
मानाप्यिभाव्यतयापाथे सामर्थ्यादिकाहस्तविरोधपरिति भाव: उक्तवाचेति एतत्सर्वेहरस्तवस्त्राधेनोक्तमित्यन्यअपि
त्ताः मत्त्वाहीति व्रत्यज्ञेनरहितारस्मर्थ: तोहिपथ्यबहुव्रीहियथ्यलसदेवपथ्यत्वादिति पार्श्विकमपीति वित्तमत्र
ममित्वेनव्यवस्थानात्॥ ॥इत्यलुक्समास:॥ ॥अगारत्वादीति निवेशमस्त्वेन पुंवत्वमानेवाभावहिति भाव: पद्धितोमारो
लेपरतोहित्वलुप्त्विति नित्यस्त्रीलिंगइति इयत्रजाति: नित्यमिति ह्नेन्नात्रुत्पलमात्रेपाभावान्निति भाव: पद्धितेस्या
नकपित्वकमित्यमेरशोनकस्यात्रतिप्यकृत्वामकल्पो विद्वित्समासरतिप्यकल्पव्यामलकोविशेषण्यविलिंगतमपि

न्नसारित्वतरस्तारस्मान्नित्यस्त्रीलिंगेतिलक्ष्यते मायंतुशव्दस्त्रमनपर्यापल्वंतिप्यफलत्वाप्यावर्तो पिस्त्रीलिंगोनिर्दे
शोवचनत्वद्वयेनेतिप्राहु तदेपिनवि मवर्णपेगाप्यामित्यस्मात्किंमप्रयोपनेसर्थ: इतिरिमिति शार्यत्वपदवि
क्तिरुपामपेतिपाठप्रातिशंकने पुंवत्प्रवोधेति पुंवद्भावाभावप्रसंगस्पर्थ: तस्य लेपुवद्भवरवोधाहलमुचितोनल
रीर्घरितिभाव:समाधत्ते मवर्णपूणागदिति एवंचत थाविवक्षायवविहतत्वपाद:सिद्धे हस्वविकल्पविधानसामर्थ्या
त्सरेरोर्घस्मृतय कृतपूर्वमार मित्यारोगपचापहकर्णविवक्षेयैवविहतत्वादेस्मात्यैनपुंसकविवक्षकलात
स्वतापिपरत्वतपरिविशिष्टस्त्रीत्वविवक्षाया स्तार्थपदरिपिपञ्चलिंगापत्वविवक्षितंतत्कार्यमंतरगामित्यपराधर्य:
इतिहतिपयेपाजनताकल्पेशव्दोतथापिमतत्तविषयेस्यायंमान्यायामजूकत्वीहिपरोर्थ: प्रकृतेनसाधुत्व
निपामकइति इमस्तसपेति वीमात्रिकुपादाशोरपाठभावादितिभाव: संख्यैकवचनादितिशास्त्र वीसाविभागा
दिति सुपलपेलुप्तिवे चाद्धिप्यइति तद्वपर्वपरस्पलोविगोध्यतामृ:तयहत्तमकृ:मात्रस्यप्रपदेलाभावादि
तिवोध्य समयत्तगांशपत्थकमतां मत्त्वकार:रापष्टकतोच पेयइति विपत्रमितिपत्तद्दमकारणचेत्सविपोदर
स्यप्रयामइति ततकृतोचेसपिवोध्यं अव्ययमिति तिर: तत्प्रकारामित्यन्ये कर्मेतिहारद्दशतिकेचा

२६
२७

लघु०

अपत्यात्मवत्तेनतर थेपीति भावः करति अविधिविधायेविलित्वं इत्याहि म्रोकस्यापीति नेवहृतानामाद्
मः तिहेत्वारीविपर्ययाहितारिम्नेकस्येत्यर्थः अनेकधेति उत्पाद्यत्वेन पान्यत्वेलेकोपस्त्वोत्कलहायसपाति
।किवार्यमवोणाहित्वेवमित्यर्थः तकानेत्यत्वमितिमनोप्युक्तभ्रमो तेनमकामः समानाइनितिह ति
पातनपहिति एषोइत्यादिसुविशिष्यार्थादिस्यार्थसमासमसवेदं तेनोवृष्णकर्तव्यमित्याहिसिद्धिः मोमस्य
सोपांशः परन्त्रितिमत्रस्येनमांमश्तमेत्याहि वार्तिकेनापिसप्रपादः अनभिधानात्तातत्पर्णमस्यमा ध
निर्वाहइति वेनकार्यविशेषमत्वताहिशेषपरत्वेवेति भावः आत्मोपापामिति तत्रमेवमपरकेनतावावि
तिभावः कथमिति हैवारिकिमतोहारपरमपाराः कथमाधुरित्यर्थः इत्याहरिति शेवारद्धमरिगारिति
म्बादिरित्रीतिमत्रेमाष्यमपोगाहिशितिवोध्य तत्स्कस्यस्यापीति एकदेशविकृतत्मापेनवहापालप्यर्थः ग्ग
वकस्योपलितत्परघटितवानिकामित्यर्थः चेत्वाघीनान्यस्पेति नवोत्तरपदत्वेव्रीतिनिषेधालकथमगाशावृस
पहत्वे प्रत्यामत्तोत्तरपदस्याकापिल्यएवतस्मद्देतीत्वित्यत्रविस्तरः वेवमोपगविनागादिति रूपकपेती

सुन्॥ ॥ ॥इतितत्पुरुषोऽव्ययविधयः॥ ॥ ॥समर्थाप्ते खलुप्विवीनाहीति तेनहितार्थे
परिवर्गाम्येवपहातारसेवेथहतिज्ञाप्यतेइति निहवनेनाहुसत्तेः कुन्तितइतिभाष्योक्तेरिसा सिद्धेतिभावः
किंतत्तवेव्यपसम्यथकाम्यिकवकेलेपिभावानुष्ठानेधर्माधिकोरहितमित्यादिः अयथलवेत्रीयहिसप
क्रमितिनोक्ते कोनाञ्चेयम्बपानोभमानेइतिहिल्लोपवारगार्थतस्यनियत्वान्वेयगोक्रशः स्यादित्यप्य
प्यिवितत्वेध्यं परिगणेनावेति श्यमप्यत्वपपुक्तिः अतत्परमाप्यमत्यत्यास्याने प्पिनशेषः एवमुक्तमि
ति प्यत्रिनपुंसककत्वापनिवरेमे इत्येविहहत्तोशवइतितरन्योधइतिभावः पारिषदत्वेसति नचपरा
दाहोइत्युक्तरपमपत्यविशेषत्वतस्त्राः सामान्यशब्देनतहिशेषसमग्रहातरविशेषत्वनस्पशामत्यपत्वेवि
शेषपरिपाराननवाधिताथकमनस्पपत्वमितिभावः हिरत्माहितिति। किञ्जतादितिशेषएवमहिते
रपि ङीपिकृतेइति किञ्जताम्यामितिविशेषः नपरोनेति पर्वत्वासिद्देनेतिनिषेधाम्यत्वेष्यः निवी
हइति घावः पितेपिम्राधारिपादाहाविमितिभावः स्त्रीसंदलितानाशियंनाकाश्यपत्वादितिन्पाय

२५०

नचोध्यं चात्र तत्प्रयोगोपि प्रागुपपादितदिशा हरत्तादिरीत्या प्रमाद इत्येवेति तत्तुं पाप्याः प्रामतीति विशेषदिकत्र
योगानिर्वाहस्तच्छंदस्यत्वाद्दित्येमे आहरिति पुंलक्षेत्येन तत्र भाष्यप्रसर्वत्र योगजाद्दिमस्योगोपरितिउक्तः
अपवाद इति बाधइत्यर्थः तत्पवादं चाद्दीनामापाद पार्थविशेषलक्षणाद्दिति एवं विप्रतिषेधेन
वाधक इति भावः उत्सर्गस्तत्त्वाद्दिति उत्सर्गेनेनत्वना वितहालि धेनो शितितत्वं तवि विज्ञापनातेन सत्रेणा इति
द्वैमितिभावः स्वत्वसमन्वंद्वत्युक्तेनं अव्यवेंनरागितिबोध्यं तत्संभयत्ताह एकमितरथरिति वैयथइति द्विवि
तइति प्रकरणोइतिशेषः स्वत्वद्वमितिविचोत्पत्ति त्वाता शितिवा तिकेवा तिकृत्यविकइतिभाष्यो
दाहरणात्स्वत्वाच्चकोपधा शितिमकर्मकोमि स्यविके मत्वेत संख्याप्रकृतेः स्वत्ववाचकादिति वाच्यं कथाद्रुकइति
नेहमाभूदेवार्तिक इति भाष्याच्चसत्तत्प्रकरणस्थभाष्यभाषामा गपच्चवार्तिके विस्वत्वं गीकारादि
तिभावः॥ ॥ इत्यपत्याद्दिविकाराणामपवादमात्रप्रकरणात्मसयः॥ ॥ सामान्यापेक्षमिति क्लीपुंसा राम
भ्यामितिपोगापेक्षमित्यर्थः हेतुत्वमिति नतु स्यात्नस्तबंधः कसयोदर्शनस्मै वस्तु कालत्वाप्यानेत

तिगुणवचनहेतोरर्थं नत्राहुरुक्तगदप्रत्ययाद्दिमात्रेकार्थस्यमुक्तारानंगुणगतिनो
रभेदविवक्षायांगुणेपरत्वेननतद्धितांतत्वेभेदविवक्षायांमतुपोनोमेधावेनवातिकस्यो
करीत्यानाख्येयत्वान्नानानेकं द्रव्याणिनामाधि [illegible] तनस्राहागुणवेजिता
देशनीगुणकापंनीनतुतेषांनापितेनैघकिताशोस्त्राहजातोतिसहहुए निजातेविशेष
र्णनन्वेवं कटादिविकारात्मनसादेनस्राहकनादेतिकटादिश [illegible] तरध्येनारख्यातह
चिनाप्रियर्थंचत्वंगुणचितरप्राणत्ताथावकुवारेइतिविधेयं रप्रातिरूपयाभागा
पाहैनदिति लक्षणापितिउच्चेलनरितिलक्षणांतरंचेप्रापिवोध्यं यद्यपि ह्यपि तदपित
मितनयायोजितते प्रापिकेपररी स्वाश्राह कह्हितिनतुस्त्रीकरी [illegible] तमतश्राहण
ण्हतेतिकिंदिनितिसंबंधानुपरेतिस्वनेनचउतत्स्वणगामावे [illegible] णाधिकार
केप्पनाप्रतिप्रसवं तपनश्राहोतइति [illegible] कदिकापादितिउगी [illegible] वानश्राहोणादोति राम

कथं लक्षणमत आह सुरन्नेहातिप्रसंगाभावादेकं कामो निकल्पे विकल्पे एवं ज्ञानवादिति भावः

नन्वपलापि कल्पनानुहेन तु प्राप्तमत आह उक्तमिति यत्र लक्षणार्थं तु नेति प्रवृत्त्यादि हेतुना

हेतुनीतिपरिभाषया अथ लक्षणानाभावादिति प्रवृत्त्येवेति अवयवलक्षणस्येतिनाशेतिभावः

ननु वचनाद्यर्थेनेत्यर्थस्यानन्तमत आह नेतिनिनु प्राप्तिमतेनेत्याह कोनो मि स्वपरोक्षेणात्र

कि द्विगुणमत आह नीत्यानव्याप्तिः सुखानि शब्दे वक्षयधिकरणाभिप्रायाधुविविनिहरदन्नाहंगता

यहो अपुनेरुक्ति एते न यथा श्रुतार्थं गमयति इत्युक्तावन्यत्र प्रमाणादिकं ज्ञेयाः कोकनदच्छायविरम

मरदाहमोगोनि प्राचार्यादिविकल्पेन इह विकल्पेन गुणोऽनेकहेतुरूपं टन्नरतिविशेषणमात्रावत्

नन्वहणाचनच संसारेनेदं कथयत इत्यादाय प्रतीयतेन नलं च रतेन तात्पर्यनिश्चयेऽहं

हेतावि ज्ञानाविशेषणतामात्रेन नशं पयायाति एतदेनत्रयायातं प्रतीयतेऽन्वयः प्रयोगः

दि ज्ञापनं तैयं तु संतानानिकियायपशाहारे दत्तत्त्वेन विवक्षिताः चेत्तुमूपाशकानां प्रत्युत्तमे

इति भाष्यपदार्थ लोचनयानर्थे वेलायामिति प्राचीनं संसारमनंदस्यदिस्याहात्रेतिसंधे

रर्थेन रश्मताते व्याहकत्रेमानिनेनेह तत्रतो वाक्यादेन नलोनेगा वमानेहतुतावत्तुप्लोपान्नारन्व

दर्मनं तं कोस्य दृष्टः एवं च नामानाहहं त्वाद्गुक्तः इति मत्वपनहिं तु तनमाहवाउ नारेकानिदु गाद्यवनेपश्चै

ननवभावमकृतीवनिहत्वाहात्प्रथमेतिनचत तसमृद्धयाचेले यानभावः विकल्पाथे नेत्रियमे

वह्नीलाभेनतत्मगयादितत्वार्थे हितिवाक्यं अयतलक्षणानहमालक्षणार्थे तत्र यं चणामविक्रमतीतिमा

प्रसाधनापेनतलक्षतत्त्वं गौकायात्र निवहतो नानेकार्थक त्वानितितत्रायः तदाहलक्षणविशि

एतेनमापविरोधे नहो त्वंतदाहविकल्पेति मूलादिदृष्टवन्नाहि हुंतमाहपरे तितितलक्ष्णनदथे

लेप्याहि हुंतत्वेप्याहहुतो वेतिपरर्थे तत्वेनेकंतदसध्यादि द्रिमाहविनेतिक्रमादित्ताकेने गौया

तितौ मानविमादि रोनिष्यानतत्र समुद्धमस्यतरोचमाहपं च यतत्र रतिच संचेनेतद्वितेनच अतएव

नया सौजत्रकमेगेतरसमुद्धपादेवर्तने नामात्रोषीहरदर्वोपक एवेतितेनामाविरोधादि

नाहबधवत्तलक्षणानी यरलः अतरवाहचकार इति नत्र प्रमयवविमोपं वनोचितमतत्राह मर्की

नितव्यतत्तविवसयेतिभावः इव्यवचमानेनोपपत्यर्थे निमामाहहूनेतितिअनतिप्रसंगपावेधौ

ंच प्रोक्तप्रतत्राह तत्रापि तत एव अविकल्पेति भावः इत्थं च तासां [illegible] प्रत्यक्षे [illegible] तत्राह इत्येति
अन तिस्र इति तत्राह इत्यपेक्षेति ननु चक्तत्वप्रयुक्तप्रमितिश्लोके इति अत्र शब्देन नन्वेवं नाधिकारे [illegible]
का न केवलं [illegible] तत्राह [illegible] निर्णीतमिति किं चलत्वात् द्विविधप्रयोगात् अत एवाह तत्र च नेति
[illegible] नं चैवं [illegible] तत्राह [illegible] इति तत्र [illegible] श्लोकं च लक्षितं यावि [illegible]
क [illegible] इति तदितिकाशिकायां तथा [illegible] श्लोकं पचतीति एते [illegible] न दृष्टत्वा
[illegible] इत्यादि [illegible] काशिकायां [illegible] इति
[illegible] हा [illegible] हाथा इति ननु [illegible] इत्यत्र [illegible] श्लोके तत्राह [illegible]
[illegible] लक्षणं । एतेन पूर्वं [illegible] इत्यादि [illegible] ननु पूर्वं [illegible]
द्वितीयाचेत्येवाह [illegible] इति [illegible] अर्थे [illegible] इति [illegible] विधानार्थं
[illegible] पूर्वविधान [illegible] बोधनार्थं [illegible] इति [illegible]
[illegible] एवमत्र [illegible] इत्येवं [illegible] तत्राह [illegible]

[illegible] इति मान्य [illegible] चेन्नाह [illegible] इत्यत्र [illegible] किं च [illegible]
[illegible] कं बाधितं [illegible] इति [illegible] इति तत्र [illegible] नाह [illegible]
[illegible] वचनत्वात् तत्राह [illegible] इति [illegible] वचनत्वात् [illegible] वाह [illegible]
[illegible] इति [illegible] तत्राह [illegible] इति [illegible] सूत्रोक्ते [illegible] एव न
[illegible] इति [illegible] नवीन [illegible] तत्राह [illegible]
[illegible] इति [illegible] इति [illegible] विंशा [illegible]
[illegible] इति [illegible] पाठे [illegible] इत्यादि [illegible]
[illegible] इति [illegible] इति साधु [illegible] इति [illegible] शाक
[illegible] चं [illegible] इति [illegible] शब्दे [illegible] शब्दे शब्दे
[illegible] चं [illegible] तत्राह [illegible] इति

ति त्वानुरूपकालक्षेक वड्डआहि न वाहुचनायाहस्याचडानस्य स तेमनन सुहवेनुनाम्य प्रज्ञाज्ञा
मशक्तोतिपरिशब्दहुलं हत्य स्मांयमानवेडमामाम्यधाम मूर्ख हि मिति व ह्यारिलिदाहरूण तेनि
रुता तिर त्वानुरूपकालिशेक वड्डवाहि न सुचनायाहस्याहडितिरय सजेनन सुहप्रेनुनाम्य
मम्हत्रिरिम्के कुदोम वि छायिपरंपेचप्पममाप्याहहेस्याविनिन नेवेकुतं अमपोनज्ञा
हशाप्यानितोतिअ विरोधाम्यहाक्षेतिशुभिनि लुसातिम मम्जिक पहरह प्रोमपपत्रमेवेध
इतिदंडिसाल्कांयंसागमायाहाराणा चोपेशिके नएकनपरार्श मा॰ह लेवेतिसर्वेवाक्यमि
नेम्याभेदेतिभावः अथहत्त्वथिसाहवंयोगाहेतोरितिहंसोगनिरास्यपाहसंवेधरतिरेवे
तिअयं हि हंनाशाहनाहस्यमावनाविवक्षिपाननुस्मावेकम [illegible] तिअसंमा उक्तसूत्राथों
विवपत्वादन्याहन देतिपिनान सहस्तुवयतदितिप्रहनाराहेसर्व सकलमंथना
यमाणाहपयोगेत्रेति एवेवज्म्पतनकभावविशेषस्वचेवंदेवकोप्पादेकोगतिरितन्याहदेव ९८

२८

कीर्तनआदिनाकेकयोआरक्षवएवतेइमहर्चिःकेचिदिपनेनमूहविनानन्दुग्यवाम्यालकरतिवि
नाहेकारकम्हुपमस्याहस्यानिभिङ्गवाहतिकारेपसाम्रहस्याशेपुत्रव्याहंवतेनेहस्याहेत्रा
पः हृपःपरत्वादिस्व दुर्लभाजाने आहग्नाःपतितदेवाहस्वलं [illegible] तनजकाप्यामित्येनेने
तिभावः इंरचप्रांचीमतेनोकं हिद्वानमाह वरूतरतितिअआपकेहस लगियिनचपडजेमितत
पारिभावोप्रतिअहोकपरिभाषाकारकं निकारविहितनसंसानिमिहकविभज्ञातसैवत्र
हलेनतमाव्येनेतत्राप्पव्याकअविरिदितिअनत्र नापिगोपालिकादोनांप्रतिषेधरतिवाहि
कं पहदुर्योदितिरोषः तेषामेवाहुर्गेरमर्थेरनापयेउपपदेनितनाहेमहाप्रमापादुपपद
द्दिमाहोविप्रतिषेधेनेतिवानिकंअथवाविभाषाकपदीहमापः परानपदीहमापहुदे
पयरसमादरतितत अप्या ख्यानेंचनदोषापे मयोधेतिस्त्रविहितसमापसंतानसुहम
संनावप्याम्पतोमर्थेःपिमनोममयोचिमनोमपसतुवस्यानिष्टाएवदमपविहितसमाससम
नसुहमसंवपोः अहेतिहंपवेनाहंमवहपावि प्रतिषेधाभावात्अस्यारमविधिधस्ततत

प्रवृत्तिमिति तत्रैवेन प्रमाणांतरेण प्रवृत्तेन नान्यत्वानि स्य लक्षणं नहताविरोधः केपदे नोक्तः एवं
तिकामं बोधेवाय तानया प्र विवेधकत्वात् एवं च वाह्यार्थसाधने तद्विलयानि स्य एवं फल तत्राहो
स्वताशाब्दां शाब्दैत द्विदोषे नैतावृत्ते स्यान्नातेन संकोटे स्यादि विषये तस्य लक्ष प्रकाशत्वा दि
निधावः य पक्षान्विषयो निस्तत्रै हेपे सप्त धर्मधाता तत्र तदभावेनो पपरस्परमा पएणां न रंगता नि
प्रा पकं न वा बहिः प्रमाणा मावा दुपपत्र रहस्य माह व्यां अपूर्वेवा नैकशंकनाय त यो मैथ्ये वा
त्रैकल्पतान व्याप्तिपूर्वं पक्षात्वि हुं तह्यप वार्तिकद्वयप सामान्य परम्प वे स्यादि साध्यो
द्विवार्तिक विचेत्य स्य नयो मैध्ये वा त्रिकल्पतान व्याप्तिपूर्वं पक्षादिद्वं तहस्य वार्तिकद्वयप
सामान्य परमथवेस्यादिना ध्यैन वार्तिकन चाप्युक्तमेतत्तदुक्तं स्यादि प्रतिमे धांशं मवे
नतत्प्रमाणं मानेषु ... प्रमादिन्नवेन तदंशम वादिति वादं परिभाषा पांगतिका
रकोपयपदादित्यत्र प्रमाणं मतं कात्त्विक पद्योपाधत्वेनप्रतिपदोक्त्यपरिभाषा पात्रकिस्तत्वाद
प्रतप्त्या स्वरस्त तक्ष्य मानत्वाश्यो ता मैत्रेन च कारकविभ ज्ञानेन प्रमाण प्रमात्रम हेतुत्वमेतेः स्वे राम
३२

प्रतमाह सूत्रं त्वनित्यैवेतन व्याप्तत्त्वतः पूर्वोक्तं तं तंशाम प्रयोगितिकं तत्त्वासाद्यन्तराणि ज्ञातेमार्ककै
पद रत्व नेन स्वच नाह आह कल्पत्वे स्याद्धांगा स्यापदि हुंतमा हार्थमात्रतत्र प्रमाणप्रमाणस्य एवेति
नेत हलदनिस्सत्वाधावादेवे प्रत्यर्थैः एतेन वद्रत्व पहल सैव मान ना न माना नि सद्क्रमिसिद्धोतंनि
त्वेव मंगा वेति सूत्रे गवादिस्वहा णं मंथंगो हं स्या दैसुत्य प्रदानि विहितकप्रमाणं नानुक
रण प्रत आहां वा वैनीति एतेनो कतो स्यागावादि स्वहल प्रवैव तदानिसत्वे मानानिस्य पाद संपद
स्या विरि निर्धक्षे तस्ल न त्वांशंमवे विषयदादादिरिति इति द्वैतपसेतस्य नत्वा ह्यंमवान्न आ
को त्ये रत्व नेमाहन्यि हेपि मा तरवी जं तद्यदैत पतित हमी स्ता तदयहे गोचे स्यादे हेतु रसि
स्व वेवनां नहि शिष्टिनि के चितनप देदं पद्ध पत्र एक मा गो नी स्या कौ तो त्वा वादि स्यप्स्थे हेमवतिन
का विहंमवात् एकारं तन्याह रूदरितिकौं तस्यतत्राहनेत्यहात्मेति डाले व चा सूपो तक
नेतुक्रम तस्माना गततान वद्ये ततस्य हम हाव्यो योया क्षिप तत्राह कारणे तेन दूल्मे राम
ए ति तद्विलेय नस्याव्य न एतत्स्याव स्यामा द्विवेनन प्रतना सत्ते चिह्नदां हृ क्रियेतिपरिभाषा
३३

त्वेहाद्वर्लभात् तथा च वक्ष्यमाणा होवततथेवंततंगतमेवतस्तमालीति नेत्यर्थ एतेनक
कारकतत्त्वविशेषमात्रयाहुर्याहत्तेएवयस्मिन्नाभासेतन्निर्विषयत्वंतस्या विकल्पेकवान्नवाधा
येनाविप्रतिषेधाद्दृश्य [illegible] व्यापकमात्रेतेन वीयादत्तेन एवेत्यत्त्वोलायाचेतितिके
सहैचेदंयदाहयाकैतुशेत्याद्वैशक्तुल्लंतयसेव्याह यद्वाननिविकल्पकेत्यर्थः तत्रापि एवं हतप
सेतत्स्वरूपी नो नैवनामा विस्तहत्नेवाय नेन एवेनेवायुविधि वेप [illegible] स्वापिनस्वभावि
नानिष्टवचेहत्वे [illegible] ततोनातिप्रसंगमाह [illegible] एवं [illegible] मिहनायोग एवेत्यर्थं [illegible]
साक्षेः वाह्यिक स्वभावविशिष्टत्वस्य [illegible] नरेक्षववय नेसार्थे तावत्पाप्त
दृकेकचित्तदपमानद्व्यादिः पदार्थविलक्षणे स्वार्थे [illegible] नप्रतिततया वितरावितानि स्या
हि नएवेति एतेन हस्वतुहासेः ददि [illegible] अर्पाण स्वपमर्यो सात
मात्रेयासन्निधाएपाधिटयाभ्यापात्तु याध्याकोशादाकार्या विचक्षणं आ वाणी सागनिवैधी
स्तादयासावी वीनव्येतिं नेककस्त्रकारे [illegible] स्पादेस्पिरिद्वांविद्वं वहतोनेसून्मयं

तामावेमलायवाहाहे वशेदमितित वाचलसंग्रंतंमयांमहमितमकांलंएवेवलसलाइयमेवएतेप
लमत्त्वतयनिति द्वासाधुक्तमयाकांत्रसत्तयानि सावकविकयकमितुक्तं स एपितुशेषमा
हाक्या सिनोयोनिस्वंगंतेदैतुयाठः स्वयाचहोनवाठाः न्तेचेदिस स्वसमाततेनेसस्मा
सा नत्रुते त्यादि तथेसुक्त्विलधमाहृपाणो त्याचतदर्थमाहापाणीतिशेषमानमाहानए
वेतिश्वसनतदस्यविषयकारोवेस्यर्थं मापाोपवाचमाहृतस्स चेहितिविकल्प सहोषवविः
वक्षयाकछीतुसहैकूउतिमनुसर्हतिधा तौमायवोसातुवाहोमलेत्साकेमाहृतवंतोयमित
ते नहकाहेठपहमाहेउवस्तुजेनतु स्वदोदेनसात स्वाकिंकोडाहौपवंतमात्रवण्या टाउंजो
तदवचनेक्योदुपत्ते नयहृतोहे [illegible] सत्वस्सनो नाविकमोमवर्मेसकत्माणलकोडाकत्मा
एतक्ो क्रहदत्तलराहाप्ववक्वयवेमत्तेनहाटिस्यवहिस्त्रश्नोमेयजेसाहलवाणेवेलाहेसष्मा
मषातिमावतकोटीतुलो मानदपमततुलाभेवनांहो कासे हुयाद्विलक्ष्मविवेकतसद्दतेनयोगे ॥ग॥
वतत्रतस्वेक्ष गहनाहंतानाताकिंचपूर्वत्रशालेले तापदेनयोरवपपूर्कतितरस्केवलेहे

कृत नकृतस्थानि हृ पित्मका केन बतो न हत्या नपर्व्वं कृ प रि वचप त्रा मि र्च हा दा हृ क्रों तो ता
हिति एतेन न ता का या न न प्याते स्या च प्र क्षौ क प दं क्रों न पर्वं भि ठे तिफ के नि या ता भा के ना हृ ता
ती ति व कृ त्रा हि त ले प्यद्र न सां ना नि नि ए न छा त्या न फल प्रु नर रहृ ते हि थ्यो बिका ए तु ते धा ३ नै
या नि ति हृ च म ना हु नेचेति न त्र ३ न्य र हृ न ना खे ३ क्रं । नि प त्रा न च पा चो पर्षं प च्य ना नि ति न त
ते रत नं रं ने मा नि प र क ा नि मा वि नो ध्या हृ च पूर्वे ति ए ते ना हया ना रं त्वथा हि हू पूर्व के म र न हृ ल
न प्यु त ए र्थां नि ति हृ चि तं । एवं च न न न र नु हृ क्रो च प त्र हृ ती प्या दा व ने न म वि ति कें प ट प्प त ड
व या र क हं था रे श्वा हृ ता मा वा हृ ड न्ता रं नी ति कृ त्रै वा ह्रा वा गा रं ति फ ल म त्वे रू म डु क्रं म
ते मा हा किं चेति ३ न ए र्थं वं व मा फ हृ चि त म वे नि पु न र न्त नो कें ए ते न न हि हृ नि ता नि प पा
हि म न मा हृ प ति नि वे ध नि ए हु न्या हं नं दं ना दि ति हा ह्रो पो प हृ र्ज न न न हा त्वा हैं के ति लो
कि क म व्य ह्ला प्या हा मे ति हि वै नो ति त्रं न प्य त्या र वं वा धि ना व से प्रे न ए वा हि त मा वं विश्रि
ए नवं ते ते नै व म म ा स ा त त्र त्र ना प्य वि ते पं प हृ हृ र ति पर म्या ति ए ते नं त्र ने न नि खे धे क

व्या हे रूर्थं वो नि न क्र मा नि हृ च य त न र थं व ि त म हे य म मो ति थ न ने न मू ले हृ वहे त प ए
हि न हा पी स्य र्थं हृ चि तं हं नि प्य थें नि नी पि पत नि ि र ल हृ मा मा नि चं चय त्रा हा प्या न मि नि
मा वे कृ रमा हा प्या न नि नि त्र नु वा र नि र हा प न र थं पा हो नो नि हृ व ना ह्ल ल न मा हृ ल प्य
न प न्नो पं त्रा हृ न ा र मा नि हृ पं त्र प्या पि न ने ना नि म हं या प्या है क त्रे ति ा न प्या जा नि न न्वे व प
पि ो हि ण का रं जो वि हि ं न प्या त न लो प्रं र ा ग पि ने प्य क न्न का थि ३ ने प्य त्र हृ प हृ ता भा वा न ए
वं च वा ह्रा ला भा थें हृ न क ना ते श्वे नि ड्डं व न नि के धा ना प नि र न त्रा हृ श्रा हृ लो नि नु हृ क्रं वे ल हृ ल्पे
त्रा दि ना थिता म हा दि ए ते न हृ न ला । प र्थं न धा व ने न हृ ले वा हृ ला ते नै व ना नि मां नि नि र हां
ते प्यो प स ा न का न प नु प्र व ना दि क मा हृ ति न हृ प्य भा चे न ना ति नि प्य ना भा वा र न ए व हृ
के प्या है न ड प हु व ना नि ता प्या है ड्डं व भा व च्छु व नि न प प्य त्र न हृ त्रा हृ न्न भा प्यो र हृ हा प्या प्या
प्या नङ्ग व नां तां त्रिको का नि प्य वा रे हि प्रि प्प न्य धे क्षण मा दि ति न ना भा प्य नि रे धा रिं ति ध्वन्म
न प या भा व्यं त थ्या हा त्रे नि त्रि न को के भ्वे ह प्य र्थं न न ए वा हा प्य रो नि इ दे नि ह हू मा दो लू ना दि वा

३५

एवाकहलेनतत्रचतसेषाके नसहदिवेनलोगहू २ वैनवाग्रततावाद अतएवादिसुविधिको
देवानामिप्राहै चपूर्वेनामवाक्रिमाथु: मूलतानतमाणोथैप्राह एवेचतदपो हृदवेह नौ चवृतपव
तस्यचार्थेनारेवकाचिदस्यैतिग्रयधनवोधुनयतानमशिष्यापस्यने प्रर्थै: अलौप्यादिवैवपो
पसाद्वहपवहूणशंकैवने पा... नाभिपानेविभिन्नभिप्यादि: नपोनिमिन्नामि पर्थै: लक्षण
नम माहनिप्पमितनत्रगलाका कानाभिकलपनहलौलोविस्यादहूका पान्वरतिभिप्पानपा
कतौरत्याविति कोशो न्न इस्थानपदार्थभिहावपवेत आदिना आकृतिहरीनविशेषणएहाने
नानेवौहरस्याहा पकानेनतत्रुनाकानेर्वाहपाठावपुरोननादितिदेहे पर्थै: नामैवानयव
नेरकायामाहतएवेपादिग्रातएवेप णार्थपाहं। पेचैद्रोपोनिग्राभनाकल्पपेदेनदुगे
शपाएणंभिनेत्वेनपुपार्थकालिकताभावेनजातिनपहपुवेप: एतननत्वं। एवेकंतैन
सत्पपाग्रांगीकोरस्यादिनाग्राममणवाहि: ग्रादिना क्षत्रियादिग्राहूणादौशिवापरोप
वीनादेपवि: त्पवानातसा हफलतादिनाते। णापेवेतियादश्मनहरिग्रनोलक्षणत्नतरस

पातेकाफकविपत्तिमिषपेपोपर्थ: पतुपत्नं वाभिवंवाभप धेरितितलानपैकेमानवहि
पाहंवेधत्वाणोमानहंवधोहिहंवेथिपंगामितचसमाहंवंधानचतदपेकन्नाग्रपततमापरत्रतिहप
कतहेवेतियालंमितहमकतसपव पमियामकवेनोमपन्नहंवेधकतपतीपनाथतेलनहेहेपप
गोतिमिंजूपाहाविपथंग्रवपवावपाशिभावादावच्छेवाभिपाहैवाभितिपपुशिवेइतिसत्रप
पहंमतेषोवंभेशहंननपापाहपकाथैतिएकहपततपेग्राहकापेकेतिरोक्षिनादिमनेना
हहंवधमिहंवंध: कापकेपपो, क्रियाकारकप, वैकं: ग्रुतापंमपुतापोवाक्रियापापाभिपक्षी
पनेहतिहंपजुरिदनहरिपाहपेहितिक:कशद्देनकुणलवादिशकूपपक्रियाकारकेहंवंध
कालरोहंवेमहपफलनतत:हवश्रपपापामक्रियो।श्रवपापामक्रियश्वहचविशेषणनाह
विशेषणतपपेवनिभित्रवपेववभितनहलदहंपेतेतिपाहंवंधलेननभावपवेतलक्षा
रतिनवक्षपवेनपोराधारधेपमावमूलकहंवेधामपाात हंपोगोहिनाधारापेवमूलको
पवरोनतपेवतमूलकलाततापवहंपोगेनहंवंधणयदर्थपोजनापाग्रहे तुवातहंयो

॥ सत्वतः पदार्थत्वात् संसर्गिकविषयतया तत्प्रामाण्यात् [illegible] तेषां
वं च पदेनापि संसर्गिकविषयता [illegible] येन तेनोक्तं इति [illegible] संबंध धर्मित्व
त्वा [illegible] [illegible] तत्संबंधि [illegible] एवार्थः तत्रैव प्रत्ययस्य [illegible]
वेन [illegible] [illegible] तेनैव [illegible] एकं चेति ह
[illegible] तत्र बुद्धौ [illegible] [illegible] हेतु [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible] हेतु वे
[illegible] [illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible] रम
दिति भावः [illegible] [illegible] [illegible] वृत्तितः [illegible]

[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] इति पदार्थ [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]
[illegible] [illegible] [illegible] [illegible] [illegible]

का मिति क्रमर्थो न तं स्म विमध हलायुक्तकवि शेषमाहहिति सोवेति कृमसमतानद समोगाचाह लोकाघा
दितिनउक्किकलमाह घटोदेशति नदवतानाविस्म ल्लिकार्थः कामि हिं लार्थैकमहेति तदादर्पः सर्व
दंदू समयनिमरे विविनिनकुनत्रानुचलंनोपातवाहतमतिचु गर्थीमधैं एतेनमिलिमाम यैयात पत्ता
चु निमतानं काभिनावि समसममस्मायवाये वसूदतनिमाव सुविवयपचिमरक्नोरिमसम समसानेरि
तिमाचोक्रमसमालेन स्मसाहिङ्क वाप्ता हसर्वमितितनायं समकामसमा हे दितिनसमतुमा ते म
लमस्वयोदिति समचोक्रमाव कंपसे हमाहार्थ तेनहितीयार्थ वेनचननसमाफ मादिति
शर्वं ल्लीतननो वलजो दिमासेन दिव हम समतिचेधे से समवकंमहसाहविकाले नहपद्ध
समहितुल्पाविमासा नहतासमवसा पिवे नर्थाापत्ते अत्र हेवेमेवि माके समनामिति वंधेन
तेत्र संबंधे द्वितीये समसहार्थ वेपिवि माके समत्ता संबंधे द्वितीये समसवे वर्णापत्ते चुतद
वन नकाहसोहमामेति वरिम नाम पोता विमाग मूलकादि समर्थः नामतिरी मतीतामत्र
पूर्वे लाभवहितुन हमापि तिकै पटो क्रमाहति येतिदिव लदर्थे सेना समर्थं माला नंतककस्य राम

पतिये समपातिहं कोचेमानामावेनफलहूक माणमहव वचनादाह शेष इतिवीजमोक्रमाहाहा
नापाति माहिनाय वनेस्मक हमोह सेमासप्रं हमपामाह मांहाधो तिनदा शर्पं माचोत्रं
सा हंग निच मकारा पनाहि हूं नमाहवलुत हमा हि माचोक्रमत्रों तरक व्यछेदामाकर्मा
दिस क मैकवहूच नमिति विधाल्लिके विस्मृह दि द्यासमनांमासमा दिव सयोधनः नेनपं तिराणे
रा क्रमेको विसूर्ं ममाञ्च प्रहतिवदहि शहमामवयाचितनमितिक मोदिहिमि समार्थमाहकमो
मायेति अधीगर्थ सादिदिवरसंननसत्कमर्थ नैनेतिउपक्रमसमत्रैवहस्ताङ्गरुवचनसमतदा
शमतवा तु पूर्वं नाविमरीन दोमाह कं वेति एतत अमवहितो तं नवरर्थ समानायलेमात
एवै तिनत्रनदसंबंध ए हवादे वेपर्थं क्रमयाकवोर्थेपर्थ ताहतिवदनत्र ननसंबंधे पारंमा
तैमममयादिव समपंतारसेव वदेन पर्थं ताहतिक सामापवप हि विमसमत्रो यानेमकर्नेकामर्थ
वाल्लीक सकमोदिपदेनेति भावः पारिशहे नतामे नोलिमूचिनं नतमत्रेति विमासोम हितीयापे
ती समर्थः मा वो मेवाहमदेति श्रापेनामकत्नाहमन्नचय उमवफलमाहेवं नोत उपपत्र तत्संबंधे तत्र

नत हंबंधेचेमर्थः नतमनो नोपपंक्त नएवा दिनाह प्रमाद्विलोपफलान मथ्य हलानाकतिचोवीक
केन न्वेकं कथं नत्वानह नि नो प्पो क्ता न आहोपीति ननुनहु तम्मा ला मावार्थ प्रकमन आह स्यो
नोति एतेन कर्तरि च रूतीति स्याहे चेन कर्मीकर्ण हुंमेवेपुनाकर्तेमहला दिति प्राचो र्भ्या स्मना दि
तिं पुनं कं चा याहे र्थो नरनिता साया हह्रयी गोति एनेन क नेत चकनीति स्याहे मवेपुनाक
र्मनह ला दिति प्राचोकं माको ना दिति हपुनं कं चा पाहे र्थो नरनिता साया हह्रयो गे ति एते
न कर्तरि चकनीति स्याहे चेन कर्मी कर्ण हेमवेपु न कर्म वह ला दिति प्राचो ह्न्या लो ना दिति हं
पुनं कं चा हे अर्थो नरनिता साया हमा वेहुस्या दि नयं क्त नति सा हं गाया वि शेष याह कर्त्रेति न
था हात्वा नि कविशेषोष्प्रदोष हया हर्विचे तिचे यधिकरणे हाह नहेति आदि नापपरेति नन्वे
वापहा कि हु तत्राह हिनो येतिव दमाति प्राचां मते नवत हु तं स्म त्राना वाशिहि कपेव तादि स्या ह हु
नी योति हक्के न प्राप्त हं मति मा ह्ला न एवेति त्र न्नम मा हा मा वेन नत्तं या क मा मा वादि वे समर्थः आपा एप
प्राव भा ह्रा स्म थे ति हि नो मा मा वया हि दवेति प्राचां मतेना हन्ते तिं प्र पिना हा मा हं वा को हि ति मलो

पव चने चे मेव तत्नो ह्रं आत एव वाक्ये नदाने ह त्वा र्थ लापतित्र नह ह्लिंग नेपिजाताचेक यचे
पेति दात हांपद ध्या ल नंत तक र्तेति वोधेन हस्य वाचि ना हा मा ना धिका रपा मा वा दि समर्थः नमदेलो
प्र के प्पहं चेदंपद मंत्र र्यो हि तेन मकरे तिचे यधिकरणे पि हमाः खदन्ते तिवा हमा हविरोध
क हमा हो ते दा त्रे ना प वा दं हा नि धा न द तिप्रा चो न कम्या हिं त न्द्रा प्पा विरो धा न दा हे स ल मिति पपन्न
केड न कं हि तं प्र अक्री ना मा हकर्ति तिह पके वा हहा ध्ये वे ने ति ए कमव छेद पे वा ह श स्य कृति न त त्रे तिनया
चेदं वद त्रे श सो श्र आत्रि को म विकि म द यो पश्र यो गा एव मव छेद पे वा ह ग स्या ति न त न्ने ति तथा
वेदं वद त्रे श सो श्र आमि को म कि वि दि मा दयो व श्र मो गा एवेति प्रा के अत एव न त हा पो पा हि
न कि पा वा मे व न द न्त व पा दे व प्रा चां म तं न ह कं पं क्ति ए ने ने ति त ह पा प्पि नं न ह न च पे ने स र्थः न
न्वे वं क च दि हा हि हु तत्राह हा धि कें ति ए ने ना ने व कर्म हो वा र ण र्थ कृ न न ह ण मि त प पा ह लो न वे
व प पि ति हं न भा र णा प न्द न आ हधा नो स्यैति हि न पे ह ति पा ठः नत्र त पो हि ध्ये क्र म्या र्थे न सा व
श प क ला ह ह न लो के ती ति ने न कु ती स नं न न्तु न लो के पि न क क हस्य पन ह णा य न त्र वि रो ध र णा र्थ न

त्तत्राह न लोके नीतितन्नेवमव्यु मयेन्नवह्रौ मपर्येन तत्रान्यथा नामहको मिन त्क्रियाकन्मर्थिक
पेलोः प्राप्तावपि नियमेन्यादर्नै त्वयाको प्राप्तं नाना प्राप्तमेवइति नत्वात्त्राहो मयतिमाव्यो
रूपत्वांत्मवं ध्याति न चेति अन्यथा साधान न्यापेन न त्वा दिनिमावांतत्र नगम्यकारिपयाश्रुता
हुंग नेरएतर्थ माहसद्भितांनेति नतु कृतपर्वातिति प्रयोग हलाक्त्यं पात्रार्थान तत्रा होरेनित्रुमा
वषेमादिः कापि हमहलोम हलोकयुक्तोतिम वहायमावाष्ठ कान्नहृत्तम प्रहद प्रहदप्रत्यत
मन्नि तानमद्व कारेणोपयुष्टि मनन कलेने निरोपोभ्यानुश्च क्रितानपूष हह काविकेपिनसा
हृदंनशान्क्रहतनतान मेवहिमात्र परम्पवष्टेछंन दाहतार्थुतांनेलिकिये वल हानेनदोपवृक्षा
हकौनितिषन्त्रकृत दर्वौ स्वत्र हकल प्राचां नंप्राप्तं सप्राण तत्र मात्र परहपदानेत्र दमेचफ
लमाहतेकुलाना ना पितिआपि नाहहुतं तजेनातएव न लोकेतिनिषेधाविषयकं निहंतपद
श्र क्रिनानह हकारयो। पाहक्तनक्रिया नावनेवि कनेन निषेधात् निहंत घटितो पपमांपे
मर्थेप्रातन्माभावात् एतेन तेनादिहेतुकृतीति मर्येपितिपरंपदह्रफौतु पापुकृपपालंतहितांते एन

३६

तेन क्त्वोपाशि तैहरलपकृतान्तपुकेसत्ता न्नात्रार्थं त्वावेन नामपवो दाहुत्ता नकिमितिभावः प्राच्यां
तंप्राहृतां ग प्रविरेतोगद्यं लहे पन क्रिपाह मए वेतितस्त्रिन विशेषे एव वा तत्त्वे हु तादिवेपर्यन्न
र्थं पाप्यं हंसकमुद्रि देवेवे माहृत्ता वेपादितिस्त्र एवमा प्यार्थः प्रा कां नंप्राप्तं गात्मा पाहात्रेति त्रमन्ना
प्रहिष्कृलाद हेवपितिप्रायो क्रंलंउपतिह नेरितिबद्दवैर्धेकु कमेचप्रा थे प्रकमनिराहा पाहेवपितितत्रा
हिनाकाप्रकाराश्रयोः भ्रु कृनेमान्नप कृपाहहत देहिसत्रेव धात्तोप्राप्तं मेपितिदप्रनीमाहक मेतिक्रांते
नपाव क्रांतेत प्रीक्षां मपनिएता पाहेपमितिति एवेननहुक्रि निपाह पूर्वापा प्यपहमापारतामा
पाप्यं नतो क्रिपिमहातेनेतिपापेलोपपर्थः तदितिपापांनहोमर्थः वहृतीपां तहर प्राधनहृत
पत्नोन्वयं पाव्यपितितत् प्रकारहितविषयंतयोरेवेति प्रत्येकावेचाकमके पपतुवर्तनेनतद्वेवाका
मेदेतत्संक्रमनेनहम्पादवोना कर्म्मलोकेवात्वेचवेकृमादयः प्राप्ता हेतोः कर्मकेषप एवेतिन त्रा
तुपादेक्रोविशेषात हर्वे एकारस्पनेतो त्वपपनेदृहतनिमाहिस्तत्र एवमाप्य कैपदादि प्रामा
पापादिति नान्विरंपा पो नंनमनप्रा लाविहद्धपनकार्माहतधानोदितिमिंगनेतितदा तोपारिमर्थः

एवमानुपूर्व्यमाकाङ्क्षा हेतिदितिशब्देनाभिसम्बध्यते तद्धितानिर्देशात् तलकारान्तमत्रात्य छिपिति
हिकलसञ्चोत्कर्षमा हं भाव्यानुकर्षेण निष्पत्तिनामभावात् ते दृष्टिविषयकमाण्यपपद्य
ते मन्यये नोपपद्यमानो हेतुर्द्वितीयाप्रथमोद्दिष्टार्थे लाभप्रतार्थे निवर्त्तनकारं तेनाश्रेकं
मन्यथानन्तरेव तत्स्वरूपं हेतिति स्वतन्त्रपदेवकर्त्तलघुपदं तं प्राप्तितिनहाहेतिरित्यादितत्त्वेदपि
श्रेयाहत्यो तिन्यपत्र बहुधा हेत्वादाहृधात्वोरितितेनवृद्धौहिमप्रोरनेति आत्मार्थं नामेत्यादि
प्राप्त्योक्तं स्वांगत्वाण्याहत्यप्रतितिप्रष्टं घं याहत्स्थितिघ्यानिवित्तस्थिर्यक्ष्मालंकारेप्राचांनेत्यार्थं
गन्वाध्याहृधात्वर्थेति विधिनेन त्याहृतुमन्तारितिः अन्वयाहृतमाननित्यमावाहानेयमेतिकदा
चिद्भवतिकदाचिन्नेत्यर्थे पूर्वं लोके मित्ते नान्तिम एवापि हुं नत्वादिनत्रके चिदित्यप्रकृतप्रमत्ता
हेत्येकेरितितथायकं विहित्य एवं नान्यतवक्रि सर्वपरिषेद्धमर्थं। अन्यथानन्तरंगतिः एपि चेति
भावः विशेषमाह एकमिके प्रवृत्तिर्निरोधात्तु नेने निभावः अनभिहितत्वाविशेषादाहृत्वपोस्यपि
तिम्रापि प्रावन्तरे साधं हाहा गम्यमाहृत्वधर्मे पेतिभेल हं अविशेषो विवक्षितः सर्वेष्वपि सिद्धेरम पप
३

हलकारेनियतिरूपाधिपिनतुश्रुतस्माने एवं क्वचिज्जमनेकप्रमाहके वलेनित्यादेशप्रहेतोरर्थः तथाचलो
ते पोगेनेत्यर्थो हमन्वः क्वचित्रदेशे प्याप्तिवत्वेन लक्ष्यं अविवियिभावात् तथाचलक्षणा यानवविधेयमके
तित्रितिप्राधक्रियाकर्त्तृकमेण्णो नेतिफलितं तु लक्ष्मणपर्थं तत्र प्रमाहारपदकल्पयामिवे
धहिहेतुनव्याहृतमिति एकदेश्युदाहरणं तथापदकृत्वेनाह लिडितितत्समनुप्रयोक्तारमश्लेषः तत्र प्रयो
कथ्येतिहेतोर्न लक्षणेति हुत्वरदाहेष्कारे सोनिके चेन्द्रा यो हृष्टमानकस्यास्य लंकरिष्युरिमदाह
रणमूलाङ्कुले हेतौ तापविशेष एवादाहरणं प्योतिप्योजितहृष्याभिनिवेशः यो लोदाहरणको
णाहृष्टने तिष्ठन्निति प्राहं गम्यामाहोक्तं तेतिविशेषमाहहृद्वेतिविशेषमाहेतदितिक्रोंतेतिकालो
दाहानेत्यादि अनभ्यंतेदेशनिमित्ताद्दोपतनुपदहे लक्षणासेपूर्वमविवक्षितकर्मपर्यन्तकर्मकता
पामूलत्वविवक्षायाहृलेवच भिहितेनैवकत्प्रमाणप्रकृतेः कर्तृकर्मणो रिप्रापचनलोकेति
निवेधादप्रवृत्तौ तव्हुती चैतिने माहृसातिप्रनतावप्रवृंतियमतेप्रटेस्कृतनिमित्तादिनवारेता
र्थेनानवकाशताभावादाहृपत्नेनेतिनपुंसके अपतवाभावात्मितिएवं च शेषेषष्ठीतिपनेनैव

वमूलाकृतेर्दङ्गंरहीतमितिनमूलेमस्ततामूलादिदृष्टिर्वासांगसंधनमपनाति दृष्टांतमाहव्यातिकेनचेमादिन्न
नैनमप्राप्तक्रैनक्रमयथानदर्हंगतिपूर्वैवतसंकोवमाह शेषावेति हाशेषतत्वविवक्षा दृष्टांकृत्य
मिस्मादौहिंदुपदस्मादाव न्वयनतुतथैव कुतोनानेत्याह परतो तिअन्यथानदर्हंगतिः एवैवअत
एवाहेतामितिएतेननथादृष्टिःशाल्लस्याप्रकल्पनाहंनेष्टतइतिनाव्यकृतायोगचिन्माभानादिति
भावं नत्वेकप्रमाणसिद्धव्यवहारंधाम्नि तेत्याह न एवेतिप्रागुक्तविरितनवप्रतिलक्षणंगमाप्याह
र्वेतिमानव्यवदेनमविषयतवसवरुद्धेरा नतुनैवमितिमाहनेतुविनितव्याचनतद्विकालविहितपक्षेवनाह
संफलितंत्रावश्यकंतिलिविषाति दृष्टप्रबंधमपुरुकंकालेदाहीनपनतव्यमविषयत्वेकत्वावाधावादिति
धकनपनाहबहुलेनितिशग दृष्टोवस्तुलमितिनोपपत्तेः तानिः द्वितीयेत्रात एवस्फुरनंतानिएवहेअविति
मत्रेअहातेअनुमानमाह नएवेति तथानताव्यनेननिषेधादेवेपपत्तेः नत्राभयथाहिंदुप्राचोक्तो
धेयपतिनेवतितत्रेशंहाविमतत्रावश्यकं तिनिः प्रोवेनामविषयत्वेनेमाहमतेनितिंदृष्टांतके
थाहोगमायाहान एवेतितपनदर्थकत्वाभावादेवेपपत्तेः इत्यनेनत्र एकेमनेनप्रारम्हविवीजं पम

१८

तेनत्याविनेतालिनावप्रकृतएपरतदोषप्रसक्तेर्नान्यतिरितिहेत्वहंकार्त्रेतिनतोबुद्धेनेएहहकर्मेतिदेशेषणता
काहकनेति विवक्षितिहाराकर्मादिविषयं आहिमाहदतदंप्रादिमनतोनरमाहाम्येविनितत्वी
तमाहमान्यंविवक्षितंप्राहित्वेयथाराणामाथाहप्रमाणमितितचैवप्रमाणमित्हितादिकरणावेक्रतव्यं कटस्य
दोहितेनां परंनाप्राप्यप्रतिपसप्रमाणवादिनापरनाह्योनलक्षणभावहेतोरस्वप्रकारविवादोस्वद
माचेउभयप्राप्तेः इतनेनानेनातिकेयायप्रतिरितिवाक्यं तद्भावविषयेवत्तेनोभयप्राप्तिविषयप्रमाणतेन
कर्मनिषेधवाक्यापत्तौकर्तृकर्मणोरितिमहत्वप्रकृतेमहणोभयप्राप्तिविनिःसृत्रस्पष्टचेवेपप्रमाण्यं
पनाश्राजाप्राने विशेषेतिप्रकृतप्रमाणाप्रमाणापेनवोभयोः प्रसंगेन एनोभयप्राप्तेर्वाभ्यप्राप्त
नेनोभयप्राप्तिविषयदोषान्तकृष्यानाविनितिविधानमसूत्रस्पष्टकृतआवाप्राप्तेःशब्देतिमाध्यमोदाहृतोग
र्थवदाविषयपदेष्वानत्मोभयप्राप्तिनिहप्याविधामूलामंगतेएहहुल्पावेतिअन्वीतमाहानए
वेतिअन्यथातद्दृष्टांतिः एवैवसंद्वितालस्याप्रसंगमामाहान एवेतित्रसादेवेपपत्तेः अशिवस्तु
र्थबालाभमामाहाशीरितितत्रेतत्रक्रमेणहवतर्थोतिविशेषंवकृमाहहेतादोतिविषय

ष एतिशेषः। अत एवेसप्तार्थमाहोगमवोरप्यातिभत्रमानमाह। तएवेति एतद्वारा र्थं न एवतेनस

प्राप्राप्तावादेवेत्यर्थः। सकलप्रावोर्हस्वेदप्रतिपत्तिविति हंत्रा प्रमा मो दीन थान्च वेदस्य मुपसिद्ध

नेसिन्नतानतत्राऽयथोपपत्तेरहमाश्च। सिद्धं चतन्मात्रानंतरेतदाह विसर एति सलादिरूपसिद्धा

भेविति॥ सिद्ध॥ लोके दृश्यगुणकृपादिविषयकमधिकरणं नराला रस्माहकारको निवे पदी मर्शका

निरूप्य प्रमुत्रऋते का हेतुस्त्रिमनेन [illegible] वेदमनतिप्रवृत्तामाह पर्यं [illegible] वेति लक्ष्यानसारिहरि

प्रलेकमाह [illegible] तिना हंमवाहमाचहै [illegible] ति नन्ववं तत्र लिंग वे कथं तत्र सा गोपनत्रमाह [illegible]

निश्चायो त्राल गमन [illegible] हं तमाह [illegible] नन्व चै त्रादि तु लक्ष्य लमाह किं चेति तद्वातो एति भाव

ने त एव द [illegible] त [illegible] तमाह [illegible] नि सा [illegible] वे [illegible] एवधारण्ये चेत्यर्थः एवेनप

रं [illegible] ने ना त्वन्वयवच्छेदः तथा [illegible] नव कियान्वयितेकारकाणां भाव

ना न्वयकुसुम निरपेक्षे [illegible] कत्वादृ [illegible] परं [illegible] न्वयविकल्पा पिकरणाधिकरणक चैत्र [illegible] एग

कं शयन [illegible] याद्विसा गोध [illegible] ह [illegible] तथान्वयादेवेत्यर्थः। अत एव [illegible]

[illegible]

प्रत्यर्थं शंकापि न कृतात्र तत्र असम्भवा [illegible] दोरदोषोदनादाविशेषणा असविषय प्रावी [illegible] प्रवृत्ती

नेरति भावः [illegible] कथं [illegible] सिद्धं [illegible] तआ [illegible] विशेषण्य [illegible] कायुक्ता सेणाया

माह [illegible] कापि योग विशिष्टे त्यर्थः [illegible] विशेषावच्छेदकतास्वेव घ [illegible] धा

ता [illegible] [illegible] करणम् [illegible] कर [illegible] धिकरणत्वेपर्याकं

[illegible] तथा वाधातु तकरे [illegible] किं [illegible] ह [illegible] [illegible] तविन [illegible]

कान एवं [illegible] [illegible] हेतु [illegible] चे [illegible] इति दिन [illegible]

धिकरणा [illegible] ह [illegible] [illegible] विहित [illegible] [illegible] ने [illegible]

[illegible] हलक [illegible] योग [illegible] ने ति भावः। नेत [illegible] तत्र [illegible] चार्यः कि

मधिकरणं [illegible] तत्र [illegible] व [illegible] त्यर्थ

[illegible] विशिष्टे [illegible] [illegible] व्य [illegible] विक [illegible]

विहाय [illegible] सं [illegible] ह [illegible] स [illegible] वेति अत एव [illegible] कार्याकात [illegible] ह

ति मत्तोऽपमर्थः एतेनकृतादि कुप्याधारा त्वव्यवच्छेद वर्णमांकेकास्य देहिते रूप्य का संयोगप्रारहुपर
जोवैर्दुधार स्यापुगलेव निहुपि नगलीका पतिनहाशे वः प्राक्षांतं स्मान्प्राहुपदि निमानां धोक्षा
दिनते दूप्यता संतोगमा द्वहुति नत्रहुता कार शधिका आश्रित तदे रूपत्र कृतकाधिकारात्
प्रपा कर्णक्रपनी साशेनोपक्षे त्रिकमिरूपधिकरणे काप शंकाप्रधीप लोदपात्र हा अधिगत
राते रसकृताकृदो पोहिते प्रवेति नतदंतपुतो हा पिनहि पिति व स्वेश्च व वेति वत्स्वाद्यधिक
रण तवेतिनद्वावतना चतत्रोपाशि दृष रोख्याहोमात्रा मावपि एक दृ पुरुष प्राचो क्रिये उपरि
कृष्ण उतिमा स्वेति मा अत्रपे सर्थः नाम प्रियो जपति शह चिवन्वकिं चिदिति शेषः तत्रो
पश्लोवि कंतनक वदिति तत संवेति नीति निरूप चो स्यापुरुक वस्य पालं च आदिमाकृपे
गर्गे कुलनिमा दिगोके देशे नरतो बुभो कुतुकी कहे शाखि नेगार्कु लेतथा प्रयोगः आ
दिनाप्राधकतंसं अस्मवहि तिलामी व्येगं माव्या हो व रूपादेगत्वा वाहृ एकीरे लक्ष्मणान्त दावि
गोता प्रेया धाप्तं त्सवी वृपवा वच्छेदे न तहीर एप योवाहंवं भामावाते पयपमता घटांगस्यापाह
गोणोवाति काकाधिकोरेतो गम भाग्रही नता पेशुरितिगुणपाठे नाधिकारांतरं तादियोधना एप

४०

दिति भावः एतेन तदा साविक स्पो हुके निर्ने कृ मनोतिन कापाले ह्माघर्षं स्वाधिक पधिकरणं चतु
र्थं पावि के चिदिहंतो निदेशा त्या पुतेच्या वालसलन उअक्तर्च पोर्हे दूतां ति वे शकुन्त्र इत्यादि
रुहुतनकाहार्थं तिमायो कवदूपा हैफनाना कांडूर दृ पाहेनरुतिकर्थं माहेनीति लदूदे वकृ इमा
होदेहितिश्लाता पते नर्थकुन्ने तालो नाप्यमाहतवा होति न दुष्याहन प्रेवेरं कर्मे निमा दृपपा
दिनपा व्योहू रीमापा हा दो दूरितापावत्रुम प्रपिपि पारत आहा वेतिल दृष्पा पुरोध मूलक पाह
स्पा स्वेतिकै पदृत्पहा चि वीतं नकत्रना नापान रूतिते नेति पालिगो नरखो न चक्षाधु रूं योग
ली मारिक पाखाक्षनि नावीतत्र पालिको गोपन वे नतत्वाविहि द्व आह दृत्वे पुरतेन पथाकृता
र्थं निए शाकाहवि मिने नित्र कृ त्रनेमाहावेति । नानेराप मेवाहकर्मीति पि नक्षमस्यर्थं इतिभावः
पत्यापमाखेक पं दृष्यो गरू से वो केनणाण दाहरणात् हमवा पोव्हवो वपल वव स्पा माहदृ
दु पाति प्रिया रुको रावो रति पाटः अस्पया पाते न दृलक मोदृलं एते नरूवें वां रुपावा
इति हदृश हलापुत्र मपा हलं न वें वं दृक्कापक लापे सत्याविर पपु चि तानत आहपुरुकोतितथा

ला। अनेनैवाजनपहृतावयतिनाचकक्रियाकाचकादित्यर्थः विनाश्यायाहृतायकेति तेन तथार्थं गतस्तत
त्वाविवक्षया अपमान्क्रियायाहेतेनधात्वर्थत्वस्य नतोकारहृणमितिरंगं उभयाश्रयं पृकृत्ययालेनत्वेकमु
क्रियेति तत्रतयोः भिन्नतत्ताश्रयत्वेनावचरूपया अद्दर्शकमिदं बोध्यमत्र तेन विवक्षितः एवमावत्वमिवाह
नाविशिष्टं चनिर्णीतदेशकालक्रियाश्रयनिर्णीतदेश तथा च नेदं प्रयोगः नाश्रयमिति भावः अत
आनत्यस्तदद्भेक्षत्वेनाप्यनापकत्वावगमः प्रयोदर्श नाश्रयता तथापिवदाहनाविति एवं चानिर्णीतदे
कालक्रियाश्रयानिर्णीतदेशकालक्रियाश्रयं च बुद्धिदेशकालयोः छेदकत्वेन लक्षणमिति बोध्यं। को
लिमायसोऽनाद्यावाहेदं चेति नत्वेकार्थकशब्दाद्यपेक्षालापादिस्यादीयस्तत्राह हायनेति उभयोर्व
ऊर्ध्वाहिणं अनेनलक्ष्यतेन तत्राश्रयकाललक्षणाश्याहगतवानिति प्रवृत्तिवद्धेदकावच्छेदकान्वयप्ये
त्वागिकत्वाद्गृहपदाकालावच्छेदेन स्यान विधाने तस्य निमित्त वंकलतिएतेन ग्रहपदाग
पदं न काललक्षकं हता यथा हारे ण दोह कर्त्तकस्य त्वाध्यालक्षणत्वेन यत्सत्वभावेनेतिस
न प्राप्यगाद्येनि मित्तत्वन्तुहिरुह्मा ध्योतिस्मायेमफलतो तिको स्तन्यायुक्तमयालंतस्मा   एप

४१

तेति। पदान्यर्थतः पदएवाहृतादाहकाश्येति नन्वेवं बहूनां संज्ञाकरणं व्यर्थमतआह महेतियद्यपि
ह्मपोषावंतौ यत्ये लोकेमपानेन लोपः इकारप्लाथ्यापिरन्तोऽपि यद्यपि तेनेह स्यामानामावे
नतदयाकांक्षा तथैव तु पेचंतआह नयनमेतिमायकाहाविसर्थः नन्वेवं बहूनामेव संज्ञाकरणे तदुपये
ने प्रकारतत्राह सुस्वरेति। यनुजातौ बहुवचनमिति प्राप्त्य स्वतन्त्रतथा सतिसमासेकापत्ते
वाप्यानतविशेषणत्वेच यथा प्रमवाद्यस्य किंद्रुतहतदर्च येनतदाश्रयणावेयथार्थ्यात् तत्रप्रमा
णाना श्रीतत्राह सोनामिति अनेकत्वार्थकमित्यर्थः तथा वा सकर्मकप्रयोगेनेतिभावः श्रोत्रत्वकम
ने गौरवादाह पदुतिः यद्यपितत्र एकत्वं पुंस्त्वे स्वकत्यामनंतरसमासादिनतात्यथासकर्तेनेष्टे
प नतदाह सत्त्वेनेति दुर्योरनिष्टहेतुमादिः अपि वेद्द्रुपनीयादि त्वस्य संयकं के यद्वकौलुसरं
सा युक्तिं खंडयति सामह यत्ताधाति एवमत्र च्छेद्यत्वं हतवहुत्तिः अत्रानर्थक्यापतेरसनप्रेक्षः ए
तदेवमाववछेद्यत्वं हृशमोर्वत्वं तत्रेहे तत्साह स्तलीनि यदिस्य हृनामेवस्यात्रत्यत्रलिपरेसयोग
हितोप विधानंत्यर्थे नहितत्रपरेतसीम कः तस्य हितसैवतत्रसत्त्वेरतिभावः नन्वेवं तहिवह

प्रतिहतायंतेनाप्यंऽत्र याभावात्तत्वप्रसङ्गात्
वानंप्रदं नोदयोकपंनसाप्य

नान्येवेतिनवाक्यंबहूनामपीतिनुवाच्यंपरान्तर्हेयोगमात्रस्यैवनत्रप्रसंग्यात् अत्राह बहून
मपीतित्रापिरत्वबौद्धादिसमुदायस्य नतुफलस्यक्रमेणवनचमलीसेवनत्रातिप्रसंगस्यतत्रावेस्य
कत्वादतत्राह तत्रेतिवाक्यस्यैवमादि [redacted]
८२ [redacted] कार्याणामनन्तरविधिकारस्यप्रत्याहारंयोगादेरित्यादावाधैन शब्दयो
रेवद्वयोर्व्याचितया बहुव्रीहिणानत्वबयवसंयोगस्येवाक्यस्याप्यन्तौदितिभावः योगभावादि
त्यत्रेयोऽयंतुयोःकारणेनुगमाकरणेनसमासेहयोगंतलोपेनत्वादिकारिकोद्धं अत्र प्रयो
गेऽस्य कः प्रयोगइतिप्रश्नवारणमाह तत्रेकूत्यतिनतद्देवानितिनतआदीव्यतीय औरेअनहलनहल
भावेऽनन्तरइतिआवश्यकबहुव्रीहिणा च समूहस्यैव नहुणोमानाभावात् समूहस्य
तदनुसरणापिहंयोगसंज्ञायांतत्रपरेणौकारस्य गुणेरितिहितापनिषद्हाहावेतिवादि
उत्रोचएकान्यपदार्थेत्वेनाख्यंतेवृत्तिदुराग्रहः तर्हितितद्ययांरस्यादौ हंयोगंनलोपापत्ते
र्लबहुलापकर्मपसें भावेनकौतुकाघुरुत्याग्रेविचारमत्र इत्युत्तंशेषस्यादोदोषोवो
हय ८२

ध्वानितिक्रमेणबोधइतिप्राचोक्तमेवत्वतत्राहानएवेतितत्कार्यौगाकारेवेसर्थः तथाच
तनतत्स्तत्त्वायास्वितिभावः एतद्विधयेत्राहोपूर्वतेतिप्राचोक्तसंगत्यायाहविरोहितेतितेतरमे
छे एवंवतिमीनावांयोजपानिर्दुइतिविभक्त्यर्थमाहविधायइतिनत्वम्यत्रेमाहात्रेतितत्रअनु
देतौहस्यांएवमावर्त्यमेवाहनतितितत्रबुध्यानवयविषवादाहेयान्तेतिप्राचोक्तसंगत्यायाहत्वे
तिएवेनावयवावयविभावनिराहः एवंचअव्यापितथाबोधेचकेऽरुद्धइत्यहचिवानंतरनमःउहृष
लस्यतिवाक्यानत्रकमेधात्योराजरन्तादित्वासमनिपातइतिदर्शनेनयगवतामिसाव्यानाविमि
मुक्तःकामांस्यहेंवत्वर्थे अन्येयोगःएवंव्रवेत्रगणपानधाकादाहलसेतिअर्थोयांप्रत्यारिये
जेतिवेधार्थेमत्रालाधुकदूलंतसर्वेप्यांतेबहुत्वपरिहारमितुविवितिसमाधिकाराचेष्यतोमेद
कात्पुस्यात्नुक्ति: किमर्थेमाहाधातिसर्वेविभक्त्यायवारत्वेतदनन्तरदौ स्यादितिप्राचोक्तसंगत्या
याहांतांगातिएतेनपातालपापापाबाधरत्वपालिएवेनकप्रीदिमवद्देःप्रत्ययानीभतेस्यादे
द्यपतः प्रत्यानतरकालाधनोरितिपदयोपतथाप्रांहवतचेतिसमासः कारकयोर्मध्यइतिप्रा

कोत्स्नांगमास्याहकोयल्लितिहस्तौतत्रहे त्मोहाप्राप्तापावान [illegible] काकपित्साहनत्रितिस्रयषु
तेसत्रप्राचो [redacted] त्रतांगासापाहकत्रे त्यादीनिशक्तिराहे नतद थैकफाके शहेनए
नराति कालामेदारि [illegible] तिरेपुत्राकप्पसाहंत्रा हिना ख्यानेतदेशाहनितेए [illegible] दिवसाधिकरण
कपोजनोस्रयदि [illegible] ओध: त्रातप्राहशकौतिकालात्वनोरितिप्राव: पयाङ्गुतात्रंगतेनह
कत्रै तितत: कप्त्रहदौ [illegible] सिद्धिशितिमानां प्राप्तांतरस [illegible] तकोतिशेष: त्रंशेम
लोघस्मगतिसाहत्रदितिकत्रे [illegible] फत्रसाहकनि [illegible] स्पष्टंचेदम [illegible] कमितिसूत्रेभाष्ये
निउंते [illegible] छहफलमाहात्रेतिपदत्रे [illegible] कतिव्यतासप्रोमर्थ: व: [illegible] अतिविकसण
खोरोत्रिभाव:॥ इति श्री [illegible] पनत्रर्षो:॥